
कविकुलगुरू - कालिदास - संस्कृत - विश्वविद्यालयः

कविकुलगुरु कालिदास संस्कृत विश्वविद्यालय, रामटेक
हस्तलिखित संग्रह

दाखल क्र. M 1999 विषय महाभारत
नाव. व्यासाश्रमपर्व
लेखक/लिपीकार शंकरपंडित
पृष्ठ 45 काळ शके 1614 पूर्ण/अपूर्ण

व्यासा०
१

॥व्यासाश्रमंपर्वेदं॥श्रीरस्तु॥

राम
१

॥श्रीगणेशायनमः॥ ॥जनमेजयउवाच॥ ॥प्राप्यराज्यंमहात्मानःपांडवामेपितामहाः।कथमासन्महा
राजेधृतराष्ट्रेमहात्मनि।सतुराजा--हतामात्योहतपुत्रोनिराश्रयः।कथमासीद्धतैश्वर्योगांधारीच
यशस्विनी।कियंतंचैवकालंतेममपूर्वपितामहाः।स्थिताराज्येमहात्मानःतन्मेव्याख्यातुमर्हसि॥ ॥वै
शंपायन०॥ ॥प्राप्यराज्यंमहात्मानःपांडवाहतशत्रवः।धृतराष्ट्रंपुरस्कृत्यपृथिवींपर्यपालयन्।धृतराष्ट्र
मुपातिष्ठद्विदुरःसंजयस्तथा।वैश्यापुत्रश्चमेधावीयुयुत्सुःकुरुसत्तम।पांडवाःसर्वकार्याणिसंपृच्छंतिस्म
तंनृपं।चक्रुस्तेनाभ्यनुज्ञातावर्षाणिदशपंचच।सदाहिगत्वातेवीराःपर्युपासंततंनृपं।पादाभिवाद
नंकृत्वाधर्मराजमतेस्थिताः।तेमूर्ध्निसमुपाघ्राताःसर्वकार्याणिचक्रिरे।कुंतिभोजसुताचैवगांधारी
मन्ववर्त्तत।द्रौपदीचसुभद्राचयाश्चान्या पांडवस्त्रियः।समांवृत्तिमवर्त्तंततयोश्वश्र्वोर्यथाविधि।
शयनानिमहार्हाणिभक्ष्यभोज्या न्यनेकशः।राजार्हाणिचसर्वाणिवासांस्याभरणानिच।युधिष्ठिरो

महाराजधृतराष्ट्रेस्युपाहरन्।तथैवकुंतीगांधार्यांगुरुवृत्तिमवर्त्तत।विदुरःसंजयश्चैवयुयुत्सुश्चैवकौरवः।
उपासतेस्मतंवृद्धंहतपुत्रंजनाधिपं।श्यालोद्रोणस्ययश्चासीद्दयितोब्राह्मणोमहान्।सचतस्मिन्महे
ष्वासःकृपःसमभवत्तदा।व्यासश्चभगवान्नित्यमासांचक्रेनृपेणह।कथाःकुर्वन्पुराणर्षिर्देवर्षिपितृ
रक्षसां।धर्मयुक्तानिकार्याणिव्यवहारान्वि तानिच।धृतराष्ट्राभ्यनुज्ञातोविदुरस्तान्यकारयत्।सा
मंतेभ्यःप्रियाण्यस्यकार्याणिसुगुरूण्यपि।प्राप्यंतेर्थैःसुलघुभिःसुनयाद्विदुरस्यवै।अकरोद्बंध
मोक्षंचवध्यानांमोक्षणंतथा।नचधर्मसुतोराजाकदाचित्किंचिदब्रवीत्।विहारयात्रासुपुनःकुरु
राजोयुधिष्ठिरः।सर्वान्कामान्महातेजाःप्रददावंबिकासुते।पौरालिकाःसूपकाराःसुशाय्यास्तर
कास्तथा।आरालिकाःस्नावकराराग्खाडविकास्तथा।उपातिष्ठंतराजानंधृतराष्ट्रंयथापुरा।वासां
सिचमहार्हाणिमाल्यानिविविधानिच।उपाजह्रुर्यथान्यायंधृतराष्ट्रस्यपांडवाः।मैरेयमत्स्यमांस

नाधिपः। गुरुवाल्लघुवा कार्यं गांधारी वा यशस्विनी॥ तत्स राजा महाराज पांडवानां धुरंधरः। पूजयित्वा वच
स्तत्तदकार्षीत्परवीरहा॥ तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः। अन्वतप्यत्व संस्मृत्य पुत्रं तं मंदचेतसं।
सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः। आशास्ते पांडुपुत्राणां समरेष्वपराजयं। ब्राह्मणान्स्वस्ति वाच्या
थ हुत्वा चैव हुताशनं। आयूंषि पांडुपुत्राणामाशासत नराधिपः॥ न तां प्रीतिं परामाप पुत्रेभ्यः स कुरूद्वहः।
यां प्रीतिं पांडुपुत्रेभ्यः सदावाप तदा नृपः। ब्राह्मणानां यथावृत्तः क्षत्रियाणां यथाविधः। तथा विट्शूद्रसंघा
नामभवत्स प्रियस्तदा। यच्च किंचित्तदा पापं धृतराष्ट्रसुतैः कृतं। अकृत्वा हृदि तद्भावं तं नृपं सोन्ववर्त्तत॥ य
श्च किंचिन्नरः कश्चिदप्रियं वांबिकासुते। कुरुते द्वेष्यतामेति स कौंतेयस्य धीमतः॥ न राज्ञो धृतराष्ट्रस्य न
च दुर्योधनस्य वै। उवाच दुष्कृतं कश्चिद्युधिष्ठिरभयान्नरः। धृत्या तुष्टो नरेंद्रः स गांधारी विदुरस्तथा। शौ
चेन चाजातशत्रोर्न तु भीमस्य शत्रुहन्। अन्ववर्त्तत तं चापि निश्चितो धर्मजो नृपं। धृतराष्ट्रं च संप्रेक्ष्य स
दा भवति दुर्मनाः। राजानमन्ववर्त्तत धर्मपुत्रममित्रहा। अन्ववर्त्तत कौरव्यो हृदयेनापराजितः॥ ॥

॥ ॥ आश्रमवासिके पर्वणि॥ २ ॥ चैत्राम्॥ ॥ युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तथा। नांतरं ददृशू राज्ये पुरुषाः
प्रणयं प्रति। यदा तु कौरवो राजा पुत्रं संस्मार दुर्मतिं। तदा भीमं हृदा राजन्नुपध्याति स पार्थिवः। तथैव भीम
सेनोपि धृतराष्ट्रं जनाधिपं। नामर्षयत राजेंद्र सदैवादुष्टवद्धृदा। अप्रकाशान्यप्रियाणि चकारास्य वृ
कोदरः। आज्ञां प्रत्याहरच्चापि कृतकैः पुरुषैः सदा। स्मरं दुर्मंत्रितं तस्य वृत्तान्यप्यस्य कानिचित्। अथ भीमः
सुहृन्मध्ये बाहुशब्दं तथाकरोत्। संश्रवे धृतराष्ट्रस्य गांधार्याश्चाप्यमर्षणः। स्मृत्वा दुर्योधनं शत्रुं कर्णदुः
शासनावपि। प्रोवाचेदं सुसंरब्धो भीमः स परुषं वचः। अंधस्य नृपतेः पुत्रा मया परिघबाहुना। नीता लोक
ममुं सर्वे नानाशस्त्रास्त्रयोधिनः। इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ। ययोरंतरमासाद्य धार्त्तराष्ट्राः
क्षयं गताः। इमौ पीनौ सुवृत्तौ मे नागराजकरोपमौ। यावासाद्य रणे मूढा धार्त्तराष्ट्राः क्षयं गताः। ताविमौ चंदने
नाक्तौ चंदनार्हौ च मे भुजौ। याभ्यां दुर्योधनो नीतः क्षयं ससुतबांधवः। एताश्चान्याश्च विविधाः शल्यभूता
नराधिप। वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत्। सा च बुद्धिमती देवी कालपर्यायवेदिनी। गांधारी

रसंश्रयेयंवनान्यहं। वीरवल्कलभृद्राजन् गांधार्यासहितोनघ। तवाशिषःप्रयुंजानोभविष्यामिवनेचरः।
उचितंनःकुलेतातसर्वेषांभरतर्षभ। पुत्रेष्वैश्वर्यमाधायवयसोंतेवनंनृप। तत्राहंवायुभक्षोवानिराहारो
पिवावसन्। पत्न्यासहानयावीरचरिष्यामितपःपरं। त्वंचापिफलभोक्तातुतपसःपार्थिवोत्यसि। फलभा
जोहिराजानःकल्याणस्येतरस्यवा॥ युधिष्ठिरः॥ नमांप्रीणयतेराज्यंत्वय्येवंदुःखितेनृप। धिग्मामस्तु
दुर्बुद्धिंराज्यासक्तंप्रमादिनं। योहंभवंतंदुःखार्त्तमुपवासकृशंभृशं। यताहारंक्षितिशयंनविंदेभ्रातृ
भिःसह। अहोस्मिवंचितोमूढोभवतागूढबुद्धिना। विश्वासयित्वापूर्वंमांयदिदंदुःखमश्नुथाः। किंमेरा
ज्येनभोगैर्वाकिंयज्ञैःकिंसुखेनवा। यस्यमेत्वंमहीपालदुःखान्येतान्यवाप्तवान्। पीडितंचापिजानामि
राज्यमात्मानमेवच। अनेनवचसातुभ्यंदुःखितस्यजनेश्वर। भवान्पिताभवान्माताभवान्नःपरमोगु
रुः। भवताविप्रहीनाहिक्वनुतिष्ठामहेवयं। औरसोभवतःपुत्रोयुयुत्सुर्नृपसत्तम। अस्तुराजामहाराज
यंचान्यंमन्यसेभवान्। अहंवनंगमिष्यामिभवान्राज्यंप्रशास्त्विदं। नमामयशसादग्धंभूयस्त्वंदग्धुम

र्हसि। नाहंराजाभवान्राजाभवतापरवानहं। कथंगुरुंत्वांधर्मज्ञमनुज्ञातुमिहोत्सहे। नमन्युर्हृदिनःकश्चित्सुयोधन
कृतेनघ। भवितव्यंतथातद्धिवयंचान्येचमोहिताः। वयंपुत्राहिभवतोयथादुर्योधनादयः। गांधारीचैवकुंतीचनिर्वि
शेषमतेमम। समांत्वंयदिराजेंद्रपरित्यज्यगमिष्यसि। पृष्ठतस्त्वानुयास्यामिसत्येनात्मानमालभे। इयंहिवसु
संपूर्णामहीसागरमेखला। भवताविप्रहीणस्यनमेप्रीतिकरीभवेत्। भवदीयमिदंसर्वंशिरसात्वांप्रसादये। त्व
दधीनास्मराजेंद्रव्येतुतेमानसोज्वरः। भवितव्यमनुप्राप्तोमन्येत्वंवसुधाधिप। दिष्ट्याशुश्रूषमाणस्त्वांमोक्षि
ष्येमनसोज्वरं॥ ॥धृतराष्ट्रउ॥ ॥तपस्येवमनस्तातवर्त्ततिकुरुनंदन। उचितंचकुलेस्माकमरण्यगमनंप्रभो।
चिरमस्म्युषितःपुत्रचिरंशुश्रूषितस्त्वया। वृद्धंमामप्यनुज्ञातुमर्हसित्वंनराधिप॥ ॥वैशंपा॥ ॥इत्युक्त्वाधर्मराजानं
वेपमानंकृतांजलिं। उवाचवचनंराजाधृतराष्ट्रोंबिकासुतः॥ संजयंचमहात्मानंकृपंचापिमहारथं। अनुनीतुमि
हेच्छामिभवद्भिर्वसुधाधिपं। ग्लायतेमेमनोहीदंमुखंचपरिशुष्यति। वयसाचप्रकृष्टेनवाग्व्यायामेनचैवहि। इत्यु
क्त्वासतुधर्मात्मावृद्धोराजाकुरूद्वहः। गांधारींशिश्रियेधीमान्सहसैवगतासुवत्। तंतुदृष्ट्वासमासीनंविसंज्ञ

मिवकौरवं। आस्तिंराजागमत्री श्रांकौंतेयः परवीरहा॥ ॥युधिष्ठिरउवाच॥ ॥यस्यनागसहस्रेणशतसंख्येननैव
बलं। सोयंनारीव्यपाश्रित्यशेतेराजागतासुवत्। आयसीप्रतिमायेनभीमसेनस्यसापुरा। चूर्णीकृताबलव
तासोबलामाश्रितः स्त्रियं। धिगस्तुमामधर्मज्ञंधिग्बुद्धिंधिक्चमेश्रुतं। यत्कृतेपृथिवीपालः शेतेयमतथोचितः।
अहमप्युपवत्स्यामियथैवायंगुरुर्मम। यदिराजानभुंक्तेयंगांधारीचयशस्विनी॥ ॥वैशंपा॥ ॥ततोस्यपा
णिनाराजाजलशीतेनपांडवः। उरोमुखंचशनकैः पर्यमार्जत्तधर्मवित्। तेनरत्नौषधिमतापुण्येनचसुगंधि
ना। पाणिस्पर्शेनराज्ञः सराजासंज्ञामवापह॥ ॥धृतराष्ट्रउ॥ ॥स्पृशमांपाणिनाभूयः परिष्वजचपांडव। जी
वामिवातिसंस्पर्शात्तिवराजीवलोचन। मूर्धानंचतवाघ्रातुमिच्छामिमनुजाधिप। पाणिभ्यांचपरिस्प्रष्टुंप्राणोहि
नजहात्मम। अष्टमोह्यद्यकालोयमाहारस्यकृतस्यमे। येनाहंकुरुशार्दूलशक्नोमिनविचेष्टितुं। व्यायामश्चा
यमत्यर्थंकृतस्त्वामभियाचतः। ततोम्लानमनास्तातनष्टसंज्ञइवाभवं। तवामृतमयस्पर्शंहिस्तस्पर्शमिमंप्रभो।
लब्ध्वासंजीवितोस्मीतिमन्येकुरुकुलोद्वह॥ ॥वैशंपा॥ ॥एवमुक्तस्तुकौंतेयः पित्राज्येष्ठेनभारत। पस्पर्श

सर्वगात्रेषुसौहार्दात्शंशनैस्तदा। उपलभ्यततः प्राणान्धृतराष्ट्रोमहीपतिः। बाहुभ्यांसंपरिष्वज्यमूर्ध्न्युपाजिघ्रतपांडवं। वि
दुरादयश्चतेसर्वेरुरुदुर्दुःखिताभृशं। अतिदुःखाच्चराजानंनोचुःकिंचनपांडवं। गांधारीत्वेवधर्मज्ञामनसोद्वहतीभृ
शं। दुःखान्यधारयद्राजन्मैवमित्येवचाब्रवीत्। इतरास्तुस्त्रियः सर्वाः कुंत्यासहसुदुःखिताः। नेत्रैरागतविक्लेदैः परि
वार्यस्थिताभवन्। अथाब्रवीत्पुनर्वाक्यंधृतराष्ट्रोयुधिष्ठिरं। अनुजानीहिमोराजन्तपसेभरतर्षभ। ग्लायतेमे
मनस्तातभूयोभूयः प्रजल्पतः। नमामतः परंपुत्रपरिक्लेष्टुमिहार्हसि। तस्मिंस्तुकौरवेंद्रेतुतथाब्रुवतिपांडवं।
सर्वेषामवरोधानामार्तनादोमहानभूत्। दृष्ट्वाकृशंविवर्णंचराजानमतथोचितं। वाग्व्यायामपरिश्रांतंत्व
गस्थिपरिशेषितं। धर्मपुत्रस्तुपितरंपरिष्वज्यमहाभुजः। शोकजंबाष्पमुत्सृज्यपुनर्वचनमब्रवीत्। नकाम
येनरश्रेष्ठजीवितंपृथिवींतथा। यथातवप्रियंराजंश्चिकीर्षामिपरंतप। यदिचाहमनुग्राह्योभवतोदयितोपि
वा। क्रियतांतावदाहारस्ततोवेत्स्याम्यहंपरं। ततोब्रवीन्महातेजाधृतराष्ट्रोयुधिष्ठिरं। अनुज्ञातस्त्वयापुत्रभुं
जीयामितिकामये। इतिब्रुवतिराजेंद्रेधृतराष्ट्रेयुधिष्ठिरं। ऋषिः सत्यवतीपुत्रोव्यासोभ्येत्यवचोब्रवीत्॥ ॥

भा॰आश्र॰
७

॥ ॥इतिमहाभारतेआश्रमवासिके॥ ॥व्यासउवाच॥ ॥युधिष्ठिरमहाबाहोयथाहकुरुनंदनः। धृतराष्ट्रोम
हातेजास्तत्कुरुष्वाविचारयन्। अयंहिवृद्धोनृपतिर्हतपुत्रोविशेषतः। नेदंकृच्छ्रंचिरतरंसहेदितिमतिर्मम। गां
धारीचमहाभागाप्राज्ञाकरुणवेदिनी। पुत्रशोकंमहाराजधैर्येणोद्वहतेभृशं। अहमप्येतदेवत्वांब्रवीमिकुरु
मेवचः। अनुज्ञांलभतांराजामावृथैहमरिष्यति। राजर्षीणांपुराणानामनुयातुगतिंनृपः। राजर्षीणांहिसर्वेषा
मंतेवनमुपाश्रयः॥ ॥वैशंपायनउवाच॥ ॥इत्युक्तःसतदाराजाव्यासेनाद्भुतकर्मणा। प्रत्युवाचमहातेजा
धर्मराजोमहामुनिं। भगवानेवनोमान्योभगवानेवनोगुरुः। भगवानस्यराज्यस्यकुलस्यचपरायणं। अहं
चपुत्रोभगवान्पितामातागुरुश्चमे। निदेशवर्तश्चपितुःपुत्रोभवतिधर्मतः॥ ॥वैशंपायनउवाच॥ ॥
इत्युक्तःसतुतंप्राहव्यासोवेदविदांवरः। युधिष्ठिरंमहातेजाःपुनरेवमहाकविः। एवमेतन्महाबाहो
यथावदसिभारत। राजायंवृद्धतांप्राप्तःप्रमाणेपरमेस्थितः। सोयंमयाभ्यनुज्ञातस्त्वयाचपृथिवीपते।
करोतुस्वमभिप्रायंमास्यविघ्नकरोभव। एषएवपरोधर्मो [illegible] राजर्षी

राम
७

णांयुधिष्ठिर। समरेवाभवेन्मृत्युर्वनेवाविधिपूर्वकं। पित्रातुतवराजेंद्रपांडुनापृथिवीक्षिता। शिष्यवृत्तेनराजा
यंगुरुवत्पर्युपासितः। क्रतुभिर्दक्षिणावद्भिरत्नपर्वतशोभितैः। महद्भिरष्टभोगाश्चभुक्ताःपुत्राश्चलालिताः। पु
त्रसंस्थंचविपुलंराज्यंविप्रोषितेत्वयि। त्रयोदशसमाभुक्तंदत्तंचविविधंवसु। त्वयाचायंनरव्याघ्रगुरुशुश्रू
षयानघ। आराधितःसभृत्येनगांधारीचयशस्विनी। अनुजानीहिपितरंसमयोस्यतपोविधौ। नमन्युर्विद्य
तेवास्यस्वल्पोपियुधिष्ठिर॥ ॥वैशं॥ ॥एतावदुक्त्वावचनमनुमान्यचपार्थिवं। तथास्त्वितिचतेनोक्तःकौं
तेयेनययौवनं। गतेभगवतिव्यासेराजापांडुसुतस्तदा। प्रोवाचपितरंवृद्धंमंदमंदमिवानतः। यदाह
भगवान्व्यासोयच्चापिभवतोमतं। यथाहचमहेष्वासःकृपोविदुरएवच। युयुत्सुःसंजयश्चैवतत्कर्त्तास्म्य
हमंजसा। सर्वएवहिमान्यामेकुलस्यास्यहितैषिणः। इदंतुयाचेनृपतेत्वामहंशिरसानतः। क्रियतांताव
दाहारस्ततोगच्छाश्रमंप्रति॥ ॥इत्याश्रमवासिके॥४॥वैशं॥ ॥ततोराज्ञाभ्यनुज्ञातोधृतराष्ट्रःप्रतापवा
न्। ययौस्वभवनंराजागांधार्यनुगतस्तदा। मंदप्राणगतिर्धीमान्कृच्छ्रादिवसमुद्वहन्। पदानिसमही

पा२

धो॰आश्र॰
८

पालो जीर्णो गजपतिर्यथा। तमन्वगच्छद्विदुरो विद्वान्सूतश्च संजयः। स चापि परमेष्वासः कृपः शारद्वतस्तथा। स
प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः। तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा। गांधारी चैव धर्मज्ञा कुंत्या स
ह मनस्विनी। वधूभिरुपचारेण पूजिताभुंक्त भारत। कृताहारं कृताहाराः सर्वे ते विदुरादयः। पांडवाश्च कुरुश्रे
ष्ठमुपातिष्ठंत तं नृपं। ततोऽब्रवीन्महाराजः कुंतीपुत्रमुपह्वरे। निषण्णं पाणिना पृष्ठे संस्पृशन्नंबिकासुतः।
अप्रमादस्त्वया कार्यः सर्वथा कुरुनंदन। अष्टांगे राजशार्दूल राज्ये धर्मपुरस्कृते। तत्तु शक्यं महाराज रक्षितुं
पांडुनंदन। राज्यं धर्मेण कौंतेय विद्वानसि निबोध तत्। विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर। शृणुया
स्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन्। प्रातरुत्थाय तान्राजन्पूजयित्वा यथाविधि। कृत्यकाले समुत्पन्ने
पृच्छेथाः कार्यमात्मनः। ते तु संमानिता राजन्त्वया कार्यहितार्थिना। प्रवक्ष्यंति हितं तात सर्वथा तव भारत।
इंद्रियाणि च सर्वाणि वाजिवत्परिपालय। हितायैव भविष्यंति रक्षितं द्रविणं यथा। अमात्यानुपधावीथापि
त्पैतामहान्शुचीन्। दांतान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः। चारयेथाश्च सततं चारैरविदितैः परान्।

राम
८

परीक्षितैर्बहुविधैः स्वराष्ट्रे पुरवासिभिः। पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणं। अट्टाट्टालकसंबाधं षट्पथं सर्व
तो दिशं। तस्य द्वाराणि कार्याणि पर्याप्तानि बृहंति च। सर्वतः सुविभक्तानि यत्नेन रक्षितानि च। पुरुषैरलमर्थस्ते
विदितैः कुलशीलतः। आत्मा च रक्ष्यः सततं भोजनादिषु भारत। विहाराहारकालेषु माल्यशय्यासनेषु च। स्त्रियश्च
ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः। शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर। मंत्रिणश्चैव कुर्वीथा द्विजान्वि
द्याविशारदान्। विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून्। तैः सार्द्धं मंत्रयेथास्त्वं नात्यर्थं बहुभिः सह। स
मस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित्। असंवृतं मंत्रगृहं स्थलं चारुह्य मंत्रयेः। अरण्ये निःशलाके वा न च रा
त्रौ कथंचन। वानराः पक्षिणश्चैव ये मनुष्यानुसारिणः। सर्वे मंत्रगृहे वर्ज्या ये चापि जडपंगवः। मंत्रभेदे पि ये
दोषा भवंति पृथिवीक्षितां। न ते शक्याः समाधातुं कथंचिदिति मे मतिः। दोषांश्च मंत्रभे दस्य ब्रूयास्त्वं मंत्रिमं
डले। अभेदे च गुणान्राजन्पुनः पुनररिंदम। पौरजानपदानां च शौचाशौचे युधिष्ठिर। यथा स्याद्विदितं रा
जंस्तथा कार्यं कुरूद्वह। धृतराष्ट्रः। व्यवहारश्च ते तात नित्यमाप्तैरधिष्ठितः। योज्यस्तुष्टैर्हितै राजन्नित्यंचा

रैरनुष्ठितः। परिमाणं विदित्वा च दंडं दंडेषु भारत। प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर। आदानरुचय
श्चैव परदाराविमर्षिणः। उग्रदंडप्रधानाश्च मिथ्याव्याहारिणस्तथा। आक्रोष्टारश्च लुब्धाश्च हन्तारः साहसप्रि
याः। सभाविहारभेत्तारो वर्णानां च प्रदूषकाः। हिरण्यदंड्या वध्याश्च कर्त्तव्या देशकालतः। प्रातरन्यांश्च प
श्येथाये कुर्याद्व्ययकर्म ते। अलंकारमथो भोज्यमत ऊर्ध्वं समाचरेः। पश्येथाश्च ततो योधान्सदा त्वं प्रतिह
र्षयन्। हतानां च नराणां च प्रदोषस्ते सदा भवेत्। सदा वापररात्रं ते भवेत्कार्यार्थनिर्णये। मध्यरात्रे विहा
रस्ते मध्याह्ने च सदा भवेत्। सर्वे त्वात्यंतिकाः कालाः कार्याणां भरतर्षभ। तथैवालंकृतः काले तिष्ठेथा भूरिद
क्षिणः। चक्रवत्तात कार्याणां पर्यायो दृश्यते सदा। कोशस्य निचये नित्यं कुर्वथा नियतः सदा। विविध
स्य महाराज विपरीतं विवर्जयेः। चारैर्विदित्वा शत्रूंश्च ये राज्ञामंतरैषिणः। तानाप्तैः पुरुषैर्दूराद्घातयेथा न
राधिप। कर्मदृष्ट्वाथ भृत्यांस्त्वं भरयेथाः कुरूद्वह। कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः। सेनाप्रणे
ता च भवेत्तव तात दृढव्रतः। शूरः क्लेशसहश्चैव हितो भक्तश्च पूरुषः। सर्वे जनपदाश्चैव तव कर्माणि पांडव।

गोवज्ञा समभवच्चैव कुर्युर्ये व्यवहारिणः। स्वरंध्रं पररंध्रं च स्वेषु चैव परेषु च। उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर। दे
शजाश्चैव पुरुषा विक्रांताः स्वेषु कर्मसु। पात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया। गुणार्थिनां गुणः कार्यो वि
दुषां ते जनाधिप। अविचाल्याश्च ते सत्याद्यथा मेरुर्महागिरिः॥ ॥इत्याश्रमवासिके॥५॥ धृतराष्ट्रः॥ ॥मंडलानि च बुध्ये
थाः परेषामात्मनस्तथा। उदासीनगणानां च मध्यस्थानां च भारत। चतुर्णां शत्रुजातानां सर्वेषामाततायिनां। मित्रं च
मित्रमित्रं च बोद्धव्यं तेरिकर्षण। तथा मात्या जनपदा दुर्गाणि विषमाणि च। बलानि च कुरुश्रेष्ठ भवंत्येषां यथेच्छ
कं। ते च द्वादश कौंतेय राज्ञां वै विषयात्मकाः। मंत्रिप्रधानाश्च गुणाः षष्टिर्द्वादश वा प्रभो। एतन्मंडलमित्याहुरा
चार्या मंत्रकोविदाः। तत्र षाड्गुण्यमायत्तं युधिष्ठिर निबोध तत्। वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुसत्तम। द्विस
प्तत्या महाबाहो ततः षाड्गुण्यजा गुणाः। यदा स्वपक्षो बलवान्परपक्षस्तथाबलः। विगृह्य शत्रून्कौंतेय जयः
क्षितिपतेस्तदा। यदा परे तु बलिनः स्वपक्षश्चैव दुर्बलः। सार्द्धं विद्वांस्तदा क्षीणः परैः संधिं समाश्रयेत्। द्रव्याणां
संचयश्चैव कर्त्तव्यः स्यान्महांस्तदा। यदा समर्थो यानाय चिरेणेव भारत। तदा सर्वं विधेयं स्यात्स्थाने न सवि

न

चारयेत्। भूमिरल्पफला देया विपरीतस्य भारत। हिरण्यं कुप्य भूयिष्ठं मित्रं क्षीणमथो बलं। विपरीतान्न गृह्णीयात्स्व
यं संधिविशारदः। सध्यर्थं राजपुत्रं वा लिप्सेथा भरतर्षभ। विपरीतं तु ते भूयः पुत्र कस्यांचिदापदि। तस्य प्रमोक्षे
यत्नं च कुर्याः सोपायमंत्रवित्। प्रकृतीनां च राजेंद्र राजा दीनां विभावयेः। क्रमेण युगपत्सर्वं व्यवसायं महा
बलं। पीडनं स्तंभनं चैव कोशभंगस्तथैव च। कार्यं यत्नेन शत्रूणां स्वराज्यं रक्षता स्वयं। नहि हिंस्यो प्युपगतः
सामंतो वृद्धिमिच्छता। कौंतेय तं न हिंसेत यो महीं विजिगीषते। गणानां भेदने योगमीप्सेथाः सह मंत्रिभिः।
साधुसंग्रहणाच्चैव पापनिग्रहणात्तथा। दुर्बलाश्चापि सततं नान्वेष्टव्या बलीयसा। तिष्ठेत राजशार्दूल वैत
सीं वृत्तिमास्थितः। यद्येनमभिजानीयाद्बलवान्दुर्बलं नृपः। सामादिभिरुपायैस्तं क्रमेण विनिवर्तयेत्। अ
शक्नुवंश्च युद्धाय निष्पतेत्सह मंत्रिभिः। कोशेन पौरदंडेन ये चास्य प्रियकारिणः। असंभवे तु सर्वस्य यथा
मुख्येन निष्पतेत्। क्रमेणानेन मोक्षः स्याच्छरीरमिति केवलं॥ ॥इत्याश्रमवासिके ६॥ ॥धृतराष्ट्रः॥ ॥
संधिविग्रहमप्यत्र पश्यस्व राजसत्तम। द्वियोनिं त्रिविधोपायं बहुकल्पं युधिष्ठिर। कौरव्य पर्युपासीथाः

छित्वा द्वैविध्यमात्मनः। तुष्टपुष्टबलः शत्रुरात्मवानिति संस्मरेत्। पर्युपासनकाले तु विपरीतं विधीयते। आमर्दकाले
राजेंद्र व्यसर्पेत ततः परं। व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः। कर्षणं भीषणं चैव युद्धे चैव बलक्षयं। प्रयास्य
मानो नृपतिस्त्रिविधं परिचिंतयेत्। आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः। उत्साहप्रभुशक्तिभ्यां मित्रशक्त्या
च भारत। उपपन्नो नृपो यायाद्विपरीतं च वर्जयेत्। आददीत बलं राजा मौलं मित्रबलं तथा। अटवीबलं भृतं चैव त
था श्रेणीबलं प्रभो। तत्र मित्रबलं राजन्मौलं चैव विशिष्यते। श्रेणीबलं भृतं चैव तुल्य एवेति मे मतिः। तथा चारबलं
चैव परस्परसमं नृप। विज्ञेयं बहुकालेषु राज्ञा काल उपस्थिते। आपदश्चैव बोद्धव्या बहुरूपा नराधिप। भवंति
राज्ञां कौरव्य यास्ताः पृथगतः शृणु। विकल्पा बहुधा राजन्नापदां पांडुनंदन। सामादिभिरुपन्यस्य गणयेत्ता
न्नृपः सदा। यात्रां गच्छेद्बलैर्युक्तो राजा षड्भिः परंतप। युक्तश्च देशकालाभ्यां बलैरात्मगुणैस्तथा। हृष्टपुष्टबलो
गच्छेद्राजा वृद्ध्युदये रतः। अकृतश्चाप्यथो यायादनृतावपि पांडव। तूणाश्मानं वाजिरथप्रधानं ध्वजद्रुमैः
संवृतकूलरोधसं। पदातिनागैर्बहुकर्दमां च नदीं सपत्नान्नृपतिः प्रयायात्। अथोपपत्त्या शकटं पद्मं वज्रं च भा
रत। उशना वेद यच्छास्त्रं तत्रैवं विहितं प्रभो। वारयित्वा परबलं कृत्वा स्वबलदर्शनं। स्वभूमौ योजयेद्युद्धं परभू

मो तथैव च॥ बलं प्रशमयेद्राजा निक्षिपेद्बलिनो नरान्॥ ज्ञात्वा स्वविषयं तत्र सामादिभिरुपक्रमेत्॥ सर्वथैव महारा
ज शरीरं धारयेदिह॥ प्रेत्येह चैव कर्त्तव्यमात्मनिःश्रेयसं परं॥ एवमेतन्महाराज सम्यक् लोके समाचरन्॥ प्रेत्य स्वर्ग
मवाप्नोति प्रजा धर्मेण पालयन्॥ एवं त्वया कुरुश्रेष्ठ वर्त्तितव्यं प्रजाहितं॥ उभयोर्लोकयोस्तात प्राप्तये नित्यमेव
हि॥ भीष्मेण सर्वमुक्तोसि कृष्णेन विदुरेण च॥ मयाप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम॥ एतत्सर्वं यथान्यायं कुर्व्व
था भूरिदक्षिण॥ प्रियं तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि॥ अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः॥ पालये
द्वापि धर्मेण प्रजास्तुल्यं फलं भवेत्॥ ॥इत्याश्रमवासिके ७॥ ॥युधिष्ठिरः॥ ॥एवमेतत्करिष्यामि यथात्थ पृ
थिवीपते॥ भूयश्चैवानुशास्योहं भवता पार्थिवर्षभ॥ भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने॥ विदुरे संजये चैव
कोन्यो मां वक्तुमर्हति॥ यत्तु मामनुशास्तीह भवान्मद्धिते स्थितः॥ कर्त्तास्मि तन्महीपाल निर्वृत्तो भव पार्थिव॥
॥ ॥वैशंपा॥ ॥ एवमुक्तः स राजर्षिर्धर्मराजेन धीमता॥ कौंतेयं समनुज्ञातुमियेष भरतर्षभ॥ पुत्र संशाम्यतां
तावन्ममापि बलवान्श्रमः॥ इत्युक्त्वा प्राविशद्राजा गांधार्या भवनं तदा॥ तमासनगतं देवी गांधारी धर्मचारि
णी॥ उवाच काले कालज्ञा प्रजापतिसमं पतिं॥ अनुज्ञातः स्वयं तेन व्यासेन त्वं महर्षिणा॥ युधिष्ठिरस्यानुमते

कदारण्यं गमिष्यसि॥ ॥धृतराष्ट्रः॥ ॥गांधार्यहमनुज्ञातः स्वयं पित्रा महात्मना॥ युधिष्ठिरस्यानुमते गंतास्मि न चि
राद्वनं॥ अहं तु तावत्सर्वेषां तेषां दुर्द्यूतदेविनां॥ पुत्राणां दातुमिच्छामि प्रेतभावानुगं वसु॥ सर्वप्रकृतिसान्निध्यं का
रयित्वा स्ववेश्मनि॥ ॥वैशंपा॥ ॥इत्युक्त्वा धर्मराजाय प्रेषयामास वै तदा॥ स च तद्वचनात्सर्वं समानिन्ये महीप
तिः॥ ततः प्रतीतमनसो ब्राह्मणाः कुरुजांगलाः॥ क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समाययुः॥ ततो निष्क्रम्य नृपति
स्तस्मादंतःपुरात्तदा॥ ददृशे तं जनं सर्वं सर्वाश्च प्रकृतीस्तथा॥ समवेतांश्च तान्सर्वान्पौरजानपदांस्तथा॥ ब्रा
ह्मणांश्च महीपाल नानादेशसमागतान्॥ उवाच मतिमान्राजा धृतराष्ट्रो विशांपते॥ भवंतः कुरवश्चैव चिरका
लं सहोषिताः॥ परस्परस्य सुहृदः परस्परहिते रताः॥ यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते॥ तथा भवद्भिः क
र्त्तव्यमविचार्य वचो मम॥ अरण्यगमने बुद्धिर्गांधारीसहितस्य मे॥ व्यासस्यानुमते राज्ञस्तथा कुंतीसुतस्य मे॥
भवंतोप्यनुजानंतु मा च वो भूद्विचारणा॥ अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती॥ न च सान्येषु सर्वेषु राज्ञा
मिति मतिर्मम॥ श्रांतोस्मि वयसानेन तथा पुत्रविनाकृतः॥ उपवासकृशश्चापि गांधारीसहितो नघाः॥ युधिष्ठि

भा०आश्र०
१२

रगते राज्ये प्राप्तश्चास्मि सुखं महत्। तन्मे दुर्योधनैश्वर्याद्धि शिष्टमिति सत्तमाः॥ मम वांधस्य वृद्धस्य हतपुत्रस्य
कागतिः। सते वनं महाभागास्तन्मे नुज्ञातुमर्हथ॥ तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजांगलाः॥ बाष्पसंदिग्धया वा
चा रुरुदुर्भरतर्षभ। तानविब्रुवतः किंचित्सर्वान् शोकपरायणान्। पुनरेव महातेजा धृतराष्ट्रोब्रवीदिदं॥ ॥इत्या
श्रमवासिके ८॥ ॥धृतराष्ट्रः॥ ॥शंतनुः पालयामास यथावद्वसुधामिमां। तथा विचित्रवीर्यश्च भीष्मेण परिपा
लितः॥ पालयामास वस्तात विदितं वो न संशयः॥ यथा च पांडुर्भ्राता मे दयितो भवतामभूत्। स चापि पालयामा
स तथा च विदितं हि वः॥ मया च भवतां सम्यक् शुश्रूषा या कृतानघाः॥ असम्यग्वा महाभागास्तत्क्षंतव्यमतंद्रि
तैः॥ यदा दुर्योधनेनेदं भुक्तं राज्यमकंटकं। अपि तत्र न वो मंदो दुर्बुद्धिरपराधवान्॥ तस्यापराधाद्दुर्बुद्धेरभिमा
नान्महीक्षितां। विमर्दः सुमहानासीदनयात्सुकृतादथ। तन्मया साधु वापीदं यदि वा साधु वा कृतं। तद्वोहृ
दि न कर्त्तव्यमयं बद्धो मयांजलिः॥ वृद्धोयं हतपुत्रोयं दुःखितोयं जनाधिपः॥ पूर्वराज्ञां च पुत्रोयमिति कृत्वानु
जानत। इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी। गांधारी पुत्रशोकार्त्ता युष्मान् याचति वै मया। हतपुत्राव
मौ वृद्धौ विदित्वा दुःखितौ यथा। अनुजानीत भद्रं वो व्रजाव शरणं वनं। अयं च कौरवो राजा कुंतीपुत्रो युधि

राम
१२

ष्ठिरः। सर्वैर्भवद्भिर्द्रष्टव्यः समेषु विषमेषु च। न जातु विषमं चैव गमिष्यति कदाचन। चत्वारः सचिवा यस्य भ्रातरो विपु
लौजसः। लोकपालसमा ह्येते सर्वे धर्मार्थदर्शिनः॥ ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः। युधिष्ठिरो महातेजा भवतः
पालयिष्यति। अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः॥ एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः। भवंतोस्य वीरस्य
न्यासभूताः कृता मया। यदेव तैः कृतं किंचिद्व्यलीकं वः सुतैर्मम। यदेतत्तन्मदीयेन तत्सर्वं क्षंतुमर्हथ। भवद्भिर्न हि मे
मन्युः कृतपूर्वः कथंचन। अत्यंतगुरुभक्तानामेषोंजलिरिदं नमः। तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणां।
कृते याचेद्य वः सर्वान् गांधारीसहितोनघाः॥ इत्युक्तास्तेन ते सर्वे पौरजानपदा जनाः॥ नोचुर्बाष्पकलाः किंचि
दीक्षांचक्रुः परस्परं। वृद्धेन राज्ञा कौरव्य न एसंज्ञा इवाभवन्। तूष्णींभूतांस्ततस्तान्स सर्वान् बाष्पकंठान्महीपतिः॥
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत। वृद्धं च हतपुत्रं मां धर्मपत्न्या सहानया। विलपंतं बहुविधं कृपणं चैव
सत्तमाः॥ पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै। वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण ह। सोहं पुनः पुनश्चैव शि
रसावनतोनघाः॥ गांधार्या सहितं तस्मान्मामनुज्ञातुमर्हथ॥ ॥इत्याश्रमवासिके ९॥ ॥वैशंपा॥ ॥तच्छ्रुत्वा

भा॰आश्र॰
१२

कुरुराजस्य वाक्यानि करुणानि ते। रुरुदुः सर्वशो राजन् समेताः कुरुजांगलाः॥ उत्तरीयैः करैश्चापि संछाद्य वदनानि ते।
रुरुदुः शोकसंतप्ता मुहूर्त्तं पितृमातृवत्। हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजं। दुःखं संधारयंतो हि नष्टसंज्ञा
इवाभवन्। ते विनीय तमायासं धृतराष्ट्रवियोगजं। शनैः शनैस्तदान्योन्यमब्रुवन् स्वमतान्युत। ततः संधाय ते स
र्वे वाक्यान्यथ समेततः। एकस्मिन्ब्राह्मणे राजन् आवेश्योचुर्नराधिपं। ततः स्वाचरणो विप्रः संमतोर्थविशार
दः। शांतव्य बहृचो राजन् वक्तुं समुपचक्रमे। अनुमान्य महाराजं तत्सदः संप्रभाष्य च। विप्रः प्रगल्भो मेधा
वी स राजानमुवाच ह। राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितं। वक्ष्यामि तदहं वीर तज्जुषस्व नराधिपा। य
थावदसि राजेंद्र सर्वमेतत्तथा विभो। नात्र मिथ्या वचः किंचित्सुहृत्त्वं नः परस्परं। न जातु अस्य च वंशस्य राज्ञां
कश्चित्कदाचन। राजासीद्यः प्रजापालः प्रजानामप्रियो भवत्। पितृवद्भ्रातृवच्चैव भवंतः पालयंति नः। न च दु
र्योधनः किंचिदयुक्तं कृतवान्नृप। तथाब्रवीति धर्मात्मा मुनिः सत्यवतीसुतः। तथा कुरु महाराज सहितः परमो
गुरुः। त्यक्ता वयं तु भवता दुःखशोकपरायणाः। भविष्यामश्चिरं राजन् भवद्गुणगतैर्हृताः। यथा शंतनुना गुप्ता

शांबाख्यः इ
ति पाठः ५

राम
१२

राजा चित्रांगदेन च। भीष्मवीर्योपगूढेन पित्रा तव च पार्थिव। भगवद्बुद्धिना चैव पांडुना पृथिवीक्षिता। तथा दुर्योध
नेनापि राज्ञा सुपरिपालिताः। न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप। पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे।
वयमास्म यथा सम्यग्भवतो विदितं यथा। तथा वर्षसहस्राय कुंतीपुत्रेण धीमता। पाल्यमाना धृतिमता सुखं वि
दामहे नृप। राजर्षीणां पुराणानां भवतां पुण्यकर्मणां। कुरुसंवरणादीनां भरतस्य च धीमतः। वृत्तं समनुयात्येष
धर्मात्मा भूरिदक्षिणः। नात्र वाच्यं सुसूक्ष्ममपि विद्यते। उषितास्म सुखं नित्यं भवता परिपालिताः। सुसूक्ष्मं च व्यली
कं ते सपुत्रस्य न विद्यते। यत्तु ज्ञातिविमर्देस्मिन्नाह दुर्योधनं प्रति। भवंतमनुनेष्यामस्तत्रापि कुरुनंदन॥ ॥इत्या
श्रमवासिके १०॥ ॥ब्राह्मणः॥ ॥ न तद्दुर्योधनकृतं न च तद्भवता कृतं। न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः।
दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुं। दैवं पुरुषकारेण न शक्यमतिबाधितुं। अक्षौहिण्यो महाराज दशाष्टा
च समागताः। अष्टादशाहेन हता दशभिर्योधपुंगवैः। भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना। युयुधानेन
वीरेण धृष्टद्युम्नेन चैव ह। चतुर्भिः पांडुपुत्रैश्च भीमार्जुनयमैस्तथा। न च क्षयोयं नृपते कृतो देवबलादृते।

महाराज ५

भा॰आ॰श्र॰
१४

अवश्यमेव संग्रामे क्षत्रियेण विशेषतः। कर्त्तव्यं निधनं काले मर्त्तव्ये क्षत्रबंधुना। तेरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वि
तैः। पृथिवी निहता सर्वा सहयाश्वरथद्विपा। न स राज्ञां वधे सूनुः कारणं ते महात्मनां। न भवान्न च ते भृत्या न कर्णो
न च सौबलः। धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतं। लभंतां वीरलोकान्स सहायो नराधिपः। द्विजाग्र्यैः सम
नुज्ञातस्त्रिदिवे मोदतां सुखं। प्राप्स्यते च भवान्पुण्यं धर्मे च परमां स्थितिं। वेद धर्मं च कार्त्स्न्येन सम्यक् बुभावसु
व्रतां। दृष्टिप्रदानमपि ते पांडवान्प्रति ते वृथा। समर्थास्त्रिदिवस्यापि चालने किं पुनः क्षितेः। अनुवर्त्स्यति वा धीमा
न् समेषु विषमेषु च। प्रजाः कुरुकुलश्रेष्ठ पांडवान् शीलभूषणान्। ब्रह्मदेयाग्रहारांश्च परिहारांश्च पार्थिवः। पू
र्वराजाभिपन्नांश्च पालयत्येव पांडवः। दीर्घदर्शी मृदुर्दांतिः सदा वैश्रवणो यथा। अक्षुद्रसचिवश्चायं कुंतीपु
त्रो महामनाः। अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभः। ऋजुः पश्यति मेधावी पुत्रवत्पाति नः सदा। विप्रियं च ज
नस्यास्य संसर्गाद्धर्मजस्य वै। न करिष्यंति राजर्षे तथा भीमार्जुनादयः। मंदा मृदुषु कौरव्य तीक्ष्णाश्चाशीविषोप
माः। वीर्यवंतो महात्मानः पौराणां च हिते रताः। न कुंती न च पांचाली न वोलूपी न सात्वती। अस्मिन्जने करिष्यं

व

राम
१४

ति प्रतिकूलानि कर्हिचित्। भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्द्धितं। न पृष्ठतः करिष्यंति पौरजानपदा जनाः। अधर्मिष्ठा
न पि सतः कुंतीपुत्रा महारथाः। मानवान्पालयिष्यंति भूत्वा धर्मपरायणाः। स राजन्मानसं दुःखमपनीय युधिष्ठिरा
त्। कुरु कार्याणि धर्म्याणि नमस्ते पुरुषर्षभ॥ ॥वैशं॥ ॥ तस्य तद्वचनं धर्म्यमनुमान्य गुणोत्तरं। साधु साध्विति
सर्वः स जनः प्रतिगृहीतवान्। धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः। विसर्जयामास तदा प्रकृतीस्तु शनैः शनैः।
स तैः संपूजितो राजा शिवेनावेक्षितस्तदा। प्रांजलिः पूजयामास तं जनं भरतर्षभ। ततो विवेश भवनं गांधार्या स
हितो निजं। व्युष्टायां चैव शर्वर्यां यच्चकार निबोध तत्॥ ॥इत्याश्रमवासिके ११॥ ॥वैशं॥ ॥ ततो रजन्यां व्युष्टायां
धृतराष्ट्रोंबिकासुतः। विदुरं प्रेषयामास युधिष्ठिरनिवेशनं। स गत्वा राजवचनादुवाचाच्युतमीश्वरं। युधिष्ठि
रं महातेजाः सर्वबुद्धिमतां वरः। धृतराष्ट्रो महाराज वनवासाय दीक्षितः। गमिष्यति वनं राजन्नागतां कार्त्ति
कीमिमां। स त्वं कुरुकुलश्रेष्ठ किंचिदर्थमभीप्सति। श्राद्धमिच्छति दातुं स गांगेयस्य महात्मनः। द्रोणस्य सोमदत्त
स्य बाल्हीकस्य च धीमतः। पुत्राणां चैव सर्वेषां ये चान्ये सुहृदो हताः। यदि वाप्यनुजानीषे सैंधवाय सदस्य च॥ २

व

तछ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः। हृष्टः संपूजयामास गुडाकेशश्च पांडवः। न तु भीमो दृढक्रोधस्तद्वचो जगृ
हे तदा। विदुरस्य महातेजा दुर्योधनकृतं स्मरन्। अभिप्रायं विदित्वा तु भीमसेनस्य फा॰ल्गुनः। किरीटी किंचिदाहस्म
तमुवाच नरर्षभं। भीम राजा पिता वृद्धो वनवासाय दीक्षितः। दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकं। भवता नि
र्जितं वित्तं दातुमिच्छति कौरवः। भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि। दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रया
चते। याचितो यः पुरास्माभिः पश्य कालस्य पर्ययं। योसौ पृथिव्याः कृत्स्नाया भर्त्ता भूत्वा नराधिपः। परैर्विनिहतापत्यो
वनं गंतुमभीप्सति। मा तेन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनं। अयशस्यमतो न्यस्माद धर्मश्च महाभुजा। राजान
मुपशिक्षस्व ज्येष्ठं भ्रातरमीश्वरं। अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ। एवं ब्रुवाणं बीभत्सुं धर्मराजोप्यपूजय
त्। भीमसेनस्तु संक्रुद्धः प्रोवाचेदं वचस्तदा। वयं भीष्मस्य दास्यामः प्रेतकार्याणि फाल्गुन। सोमदत्तस्य नृपतेर्भू
रिश्रवस एव च। बाल्हीकस्य च राजर्षेर्द्रोणस्य च महात्मनः। अन्येषां चैव सर्वेषां कुंती कर्णाय दास्यति। श्राद्धानि
पुरुषव्याघ्र मा प्रादात्कौरवो नृपः। इति मे वर्त्तते बुद्धिर्मा नो नंदंतु शत्रवः। कष्टात्कष्टतरं यांतु सर्वे दुर्योधनादयः।

राम
१५

यैरियं पृथिवी कृत्स्ना घातिता कुलपांसनैः। कुतस्त्वमसि विस्मृत्य वैरं द्वादशवार्षिकं। अज्ञातवासं दहनं द्रौपदीशोक
वर्द्धनं। क्व तदा धृतराष्ट्रस्य स्नेहोस्मासु भवत्तदा। कृष्णाजिनोपसंवीतो हृताभरणभूषणः। सार्द्धं पंचालपुत्र्या त्वं रा
जानमुपजग्मिवान्। क्व तदा द्रोणभीष्मौ तौ सोमदत्तोपि वा भवत्। यत्र त्रयोदश समा वने वन्यैरजीजिवः। न तदा
त्वां पिता ज्येष्ठः पितृत्वेनापि वीक्ष्यते। किं त्वेतद्विस्मृतं पार्थ यदेष कुलपांसनः। दुर्बुद्धिर्विदुरं प्राह द्यूते किं जितमि
त्युत। तमेवं वादिनं राजा कुंतीपुत्रो युधिष्ठिरः। उवाच वचनं धीमान् जोषमास्वेति भर्त्सयन्॥ ॥इत्याश्रमवासि
के १२॥ ॥अर्जुनः॥ ॥भीम ज्येष्ठो गुरुर्मे त्वं नातोन्यद्वक्तुमुत्सहे। धृतराष्ट्रस्तु राजर्षिः सर्वथा मानमर्हति। न स्मरं
त्यपराद्धानि स्मरंति सुकृतान्यपि। असंभिन्नार्यमर्य्यादाः साधवः पुरुषोत्तमाः। इति तस्य वचः श्रुत्वा फाल्गुनस्य
महात्मनः। विदुरं प्राह धर्मात्मा कुंतीपुत्रो युधिष्ठिरः। इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवं। यावदिच्छति पुत्राणां
श्राद्धं तावद्ददाम्यहं। भीष्मादीनां च सर्वेषां सुहृदामाप्तकारिणां। ममकोशादिति विभो मा भूद्भीमः सुदुर्मनाः।
॥वैशंपा॥ ॥इत्युक्तो धर्मराजस्तमर्जुनः प्रत्यपूजयत्। भीमसेनः कटाक्षेण वीक्षांचक्रे धनंजयं। ततः स विदुरं धी

मान् वाक्यमाह युधिष्ठिरः। न भीमसेने कोपं स नृपतिः कर्तुमर्हति। परिक्लिष्टो हि भीमोयं हिमवृष्ट्यातपादिभिः। दुःखै
र्बहुविधैर्धीमानरण्ये विदितं तव। किं तु मद्वचनाद्ब्रूहि राजानं भरतर्षभं। यद्यदिच्छसि यावच्च त्वं गृह्यतां मद्गृहादि
ति। यन्मात्सर्यमयं भीमः करोति भृशदुःखितः। न तन्मनसि कर्त्तव्यमिति वाच्यः स पार्थिवः। यन्ममास्ति धनं किंचि
दर्जुनस्य च वेश्मनि। तस्य स्वामी महाराज इति वाच्यः स पार्थिवः। ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां स्वयं। पुत्रा
णां सुहृदां चैव गच्छत्वानृण्यमद्य सः। इदं चापि शरीरं मे त्वदायत्तं जनाधिप। धनानि चेति विद्धि त्वं क्षत्तुर्नास्त्य
त्र संशयः॥ ॥इत्याश्रमवासिके १३॥ ॥वैशम्॥ ॥एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः। धृतराष्ट्रमुपेत्येदं वा
क्यमाह महार्थवत्। उक्तो युधिष्ठिरो राजा भवद्वचनमादितः॥ स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः। बीभ
त्सुश्च महातेजा निवेदयति ते गृहान्। वसु तस्य गृहे यच्च प्राणानपि च केवलान्। धर्मराजश्च पुत्रस्ते राज्यं प्रा
णान्धनानि च। अनुजानाति राजर्षे यच्चान्यदपि किंचन। भीमस्तु पूर्वदुःखानि संस्मृत्य बहुलान्यतः। कृच्छ्रादि
च महाबाहुरनुजज्ञे विनिःश्वसन्। स राजन्धर्मशीलेन राज्ञा बीभत्सुना तथा। अनुनीतो महाबाहुः सौहृदे स्था

राम
१६

पितोपि च। न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट्। संस्मृत्य भीमस्तु वैरं यदन्यायवदाचरन्। एवंप्रायो हि धर्मो
यं क्षत्रियाणां नराधिप। युद्धे क्षत्रियधर्मे च निरतोयं वृकोदरः। वृकोदरकृते चाहमर्जुनश्च पुनः पुनः। प्रसाद
येनं नृपते भवान्प्रभुरिहास्ति यत्। तद्ददातु भवान्वित्तं यावदिच्छति पार्थिवः। त्वमीश्वरोस्य राज्यस्य प्राणानाम
पि भारत। ब्रह्मदेयाग्रहाराश्च पुत्राणामौर्ध्वदेहिकं। इतो रत्नानि गाश्चैव दासीदासमजाविकं। नानयित्वा कु
रुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु। दीनांधकृपणानां च तत्र तत्र नृपाज्ञया। बह्वन्नरसपानाढ्याः सभा विदुर कारय।
गव्यान्नपानान्यन्यच्च विविधं पुण्यकं कुरु। इति मामब्रवीद्राजा पार्थश्चैव धनंजयः। यदत्रानंतरं कार्यं तद्भ
वान्वक्तुमर्हति। इत्युक्तो विदुरेणाथ धृतराष्ट्रोभिनंद्य तान्। मनश्चक्रे महादानकार्त्तिक्यां जनमेजय॥ ॥इत्या
श्रमवासिके १४॥ ॥वैशम्॥ ॥विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः। प्रीतिमानभवद्राजा राज्ञो जिष्णोश्च
कर्मणा। ततोभिरूपान्भीष्माय ब्राह्मणानृषिसत्तमान्। पुत्रार्थे सुहृदश्चैव स समीक्ष्य सहस्रशः। कारयित्वा
न्नपानानि यानान्याच्छादनानि च। सुवर्णमणिरत्नानि दासीदासमजाविकान्। कंबलाजिनरत्नानि ग्रामान्

भा॰आ॰श्र॰
१७

क्षेत्राण्यजाविकं। सालंकारान् गजानश्वान् कन्याश्चैव वरस्त्रियः। उद्दिश्योद्दिश्य विप्रेभ्यो ददौ स नृपसत्तमः॥ द्रोणं संकी
र्त्य भीष्मं च सोमदत्तं च बाल्हिकं। दुर्योधनं च राजानं पुत्रांश्चैव पृथक् पृथक्। जयद्रथपुरोगांश्च सुहृदश्चापि सर्वशः॥
स श्राद्धयज्ञो ववृधे बहुगोधनदक्षिणः। अनेकधनरत्नौघो युधिष्ठिरमते तदा॥ अनिशं यत्र पुरुषा गणकालेखका
स्तथा। युधिष्ठिरस्य वचनादापृच्छंतेस्म तं नृपं। आज्ञापय किमेतेभ्यः प्रदानं दीयतामिति। तदुपस्थितमेवात्र वच
नान्ते ददुस्तदा। शतंदेयं शतशातं सहस्रे वायुतं तथा। दीयते वचनाद्राज्ञः कुंतीपुत्रस्य धीमतः॥ एवं स वसुधाराभि
र्वर्षमाणो नृपांबुदः। तर्पयामास विप्रांस्तु वर्षन् भूमिमिवांबुदः। ततोनंतरमेवात्र सर्ववर्णान्महामते। अन्नपान
रसौघेन प्लावयामास पार्थिवः। स वस्त्रधनरत्नौघो मृदंगनिनदो महान्। गवाश्वमकरावर्त्तो नारीरत्नमथा
करः। ग्रामाग्रहारद्वीपाढ्यो मणिहेमजलार्णवः। जगत्संप्लावयामास धृतराष्ट्रो ददद्धनं। एवं स पुत्रपौत्राणां पि
तॄणामात्मनस्तथा। गांधार्याश्च महाराज प्रददावौर्ध्वदेहिकं। परिश्रांतो यदासीत्स ददद्दानान्यनेकशः। निवर्त्त
यामास तदा दानयज्ञं नराधिप। एवं स राजा कौरव्यश्चक्रे दानमहाक्रतुं। नटनर्त्तकलास्याढ्यं बह्वन्नरसदक्षिणं।

राम
१८

दशाहमेवं दानानि दत्वा राजांबिकासुतः। बभूव पुत्रपौत्राणामनृणो भरतर्षभ॥ ॥इत्याश्रमवासिके १५॥ ॥
॥वैशंपा॥ ततः प्रभाते राजा स धृतराष्ट्रोंबिकासुतः। आहूय पांडवान्वीरान्वनवासे कृतक्षणः। गांधारीसहितो
धीमानभ्यनंदद्यथाविधि। कार्त्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः। अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः।
वधूजनवृतो राजा निर्ययौ भवनात्ततः। ततः स्त्रियः कौरवपांडवानां याश्चापराः कौरवराजवंश्याः। तासां नादः
प्रादुरासीत्तदानीं वैचित्रवीर्ये नृपतौ प्रयाते। ततो लाजैः सुमनोभिश्च राजा विचित्राभिः स्वगृहं पूजयित्वा। संपूज्या
थे भृत्यवर्गं च सर्वं ततः समुत्सृज्य ययौ नरेंद्रः। ततो राजा प्रांजलिर्वेपमानो युधिष्ठिरः सस्वरं बाष्पकंठः। वि
मुच्योच्चैर्हा महाराज साधो क्व यास्यसीत्यपतत्तात भूमौ। तथार्जुनस्तीव्रदुःखाभितप्तो मुहुर्मुहुर्निश्वसन् भा
रताग्र्यः। युधिष्ठिरं मैवमिव मुक्त्वा निगृह्यार्थान्दीनवत्सीदमानः। वृकोदरः फाल्गुनश्चैव वीरौ माद्रीपुत्रौ
विदुरः संजयश्च। वैश्यापुत्रः सहितो गौतमेन धौम्यो विप्राश्चान्वयुर्बाष्पकंठाः। कुंती गांधारीं बद्धनेत्रां व्रजंती
स्कंधासक्तं हस्तमथोद्वहंती। राजा गांधार्याः स्कंधदेशेवसज्य पाणिं ययौ धृतराष्ट्रः प्रतीतः। तथा कृष्णा द्रौपदी सा

त्यती च बालापत्या चोत्तरा सौत्तेवी च। चित्रांगदाद्याश्च याः काश्चित् स्त्रियो न्याः सार्द्धं राज्ञा प्रस्थितौ स्नाव धूभिः। तासां नादो रुदतीनां तदासीद्राजन् दुःखात् कुररीणामिवोच्चैः। ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां विट्शूद्राणां चैव सा धर्मः समंतात्। तन्निर्याणे दुःखितः पौरवर्गो गजाह्वये चैव बभूव राजन्। यथा पूर्वं गच्छतां पांडवानां द्यूते राजन्

दा॰४

कौरवाणां सभायां। यानापश्यंश्चंद्रमा नैव सूर्यो रामाः काँचिदपि तस्मिन्नरेंद्र। महावनं गच्छति कौरवेंद्रे शोकेनार्त्ता राजमार्गं प्रपेदुः॥ ॥इत्याश्रमवासिके १५॥ ॥वैशंपा॥ ॥ ततः प्रासादहर्म्येषु वसुधायां च पार्थिव। नारीणां पुरुषाणां च निस्वनः सुमहानभूत्। स राजा राजमार्गेण न्टनारीसंकुलेन च। कथंचिन्निर्ययौ धीमान् वेपमानः कृतांजलिः। स वर्द्धमानद्वारेण निर्ययौ गजसाह्वयात्। विसर्जयामास च तं जनौघं सं कुलं मुहुः। वनं गंतुं च विदुरो राज्ञा सह कृतक्षणः। संजयश्च महामात्रः सूतो गावल्गाणिस्तथा। कृपं निवर्त्तयामास युयुत्सुं च महारथं। धृतराष्ट्रो महीपालः परिदाय युधिष्ठिरे। निवृत्ते पौरवर्गे तु राजा सांतःपुरस्तदा। धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष ह। सोब्रवीन्मातरं कुंतीं वनं तमनुजग्मुषीं। अहं राजानमन्विष्ये भवती विनि

राम
१८

वर्त्ततां। वधूपरिवृता राज्ञि नगरं गंतुमर्हसि। राजा यात्वेष धर्मात्मा तपसे कृतनिश्चयः। इत्युक्ता धर्मराज्ञेन बाष्पव्याकुललोचना। जगामैव तदा कुंती गांधारीं परिगृह्य ह॥ ॥कुंत्युवाच॥ ॥ सहदेवे महाराज प्रमादं मा कृथाः कचित्। एष मामनुरक्तो हि राजं स्त्वां चैव सर्वदा। कर्णं स्मरेथाः सततं संग्रामेष्व पलायिनं। अवकीर्णो हि समया वीरो दुःखवृत्तया तदा। आयसं हृदयं नूनं मंदाया मम पुत्रक। यत्सूर्यजमपश्यंत्याः शतधेदं न दीर्यते। एवंगते तु किं शक्यं मया कर्त्तुमरिंदम। मम दोषो यमत्यर्थः ख्यापितो यन्न सूर्यजः। तन्निमित्तं हि महाबाहो दानं दद्यास्त्वमुत्तमं। सदैव भ्रातृभिः सार्द्धं सूर्यजस्यारिमर्दन। द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्षण। भीमसेनोर्जुनश्चैव नकुलश्च कुरूद्वह। समाधेयास्त्वया राजन् त्वं त्वद्य कुलधूर्गतः। श्वश्रूश्वशुरयोः पादान् शुश्रूषंती वने त्वहं। गांधारीसहिता वत्स्ये तापसी मलपंकिनी॥ वैशंपा॥ एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी। विषादमगमद्धीमान् न चाकिंचिदुवाच ह। मुहूर्त्तमिव तु ध्यात्वा धर्मराजो युधिष्ठिरः। उवाच मातरं दीनश्चिंताशोकपरायणः। किमिदं ते व्यवसितं नैवं त्वं व

म॰आ॰ ३॰
१९

त्तुमर्हसि। व्यबोधयः पुरा त्यस्मानुत्साहप्रियदर्शने। विदुलाया वचोभिस्त्वं नास्मान्संत्यक्तुमर्हसि। निहत्य पृ
थिवीपालान् राज्यं प्राप्तमिदं मया। तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात्। क्व सा बुद्धिरियं चेयं भवत्याय
च्छ्रुतं मया। क्षत्रधर्मस्थितिं चोक्त्वा नाद्य व्यसितुमर्हसि। अस्मानुत्सृज्य राज्यं च स्नुषां चेमां यशस्विनि।
कथं वत्स्यसि दुर्गेषु वनेषु च प्रसीद मे। इति बाष्पकलां वाचः कुंतीपुत्रस्य शृण्वती। सा जगामाश्रुपूर्णा
क्षी भीमस्तामिदमब्रवीत्। यदा राज्यमिदं कुंती भोक्तव्यं पुत्रनिर्जितं। प्राप्तव्या राजधर्माश्च तदेयं ते कुतो
मतिः। किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयं। कस्य हेतोः परित्यज्य वनं गंतुमभीप्ससि। वनाच्चापि कि
मानीता भवत्या बालका वयं। दुःखशोकसमाविष्टौ माद्रीपुत्रौ विमौ तथा। प्रसीद मातर्मा गास्त्वं वनमद्य
यशस्विनी। श्रियं यौधिष्ठिरीं मातर्भुंक्ष्व पार्थबलार्जितां। इति सा निश्चितैवाथ वनवासाय भाविनी। आलप्य
तां बहुविधं पुत्राणां नाकरोद्वचः। द्रौपदी चान्वयाच्छ्वश्रूं विषण्णवदना तदा। वनवासाय गच्छंतीं रुदती भद्र
या सह। सा पुत्रान्रुदतः सर्वान् मुहुर्मुहुरवेक्षती। जगामैव महाप्राज्ञा वनाय कृतनिश्चया। अन्वयुः पां

राम
१९

डवास्तां तु सभृत्यांतःपुरास्तथा। ततः प्रमृज्य साश्रूणि पुत्रान्वचनमब्रवीत्॥ ॥इत्याश्रमवासिके १७॥ ॥कुंत्युवाच॥ ॥
एवमेतन्महाराज यथा वदसि पांडव। कृतमुद्धर्षणं पूर्वं मया वः सीदतां नृप। द्यूतापहृतराज्यानां पतितानां सुखाद
पि। ज्ञातिभिः परिभूतानां कृतमुद्धर्षणं मया। कथं पांडोर्न नश्येत संततिः पुरुषर्षभाः। यशश्च वो न नश्येत इति वोद्धर्ष
णं कृतं। यूयमिंद्रसमाः सर्वेदिवतुल्यपराक्रमाः। मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया। कथं धर्मभृतां श्रेष्ठो राजा
त्वं वासवोपमः। पुनर्वने न दुःखी स्यादिति वोद्धर्षणं कृतं। नागायुतसमप्राणः ख्यातविक्रमपौरुषः। नायं भीमो त्ययं ग
च्छेदिति वोद्धर्षणं कृतं। भीमसेनादवरजस्तथायं वासवोपमः। विजयो नावसीदेत इति चोद्धर्षणं कृतं। नकुलः सह
देवश्च तथेमौ गुरुवर्तिनौ। क्षुधा कथं न सीदेतामिति चोद्धर्षणं कृतं। इयं च बृहती श्यामा श्रीमत्यायतलोचना। वृथा
सभातले क्लिष्टा मा भूदिति च तत्कृतं। प्रेक्षतामेव वो भीम वेपंतीं कदलीमिव। स्त्रीधर्मिणीमरिष्टांगीं तथा द्यूतपराजितां।
दुःशासनो यदा मौर्ख्याद्दासीवत्परिकर्षत। तदैव विदितं मह्यं पराभूतमिदं कुलं। विषण्णाः कुरवश्चैव तदा मे श्वशुरा
दयः। यदैव नाथमिच्छंती व्यलपत्कुररी यथा। केशपक्षे परामृष्टा पापेन हतबुद्धिना। यदा दुःशासनेनैषा तदा मुह्याम्य

हं नृप। युष्मत्तेजोविवृद्ध्यर्थं मयाऽऽत्मदर्पणं कृतं। न तत्र पुत्राः पौत्रा वा कुरवस्ते च पार्थिवाः। लभंते सुकृताल्लोकान्यस्मादंशाः प्र
णश्यति। भुक्तं राज्यफलं पुत्रा भर्त्तुर्मे विपुलं पुरा। महादानानि दत्तानि पीतः सोमो यथाविधि। नाहमात्मफलार्थं वै वासुदे
वमचूचुदं। विदुलायाः प्रलापैश्च पालनार्थं तु तत्कृतं। नाहं राज्यफलं पुत्राः कामये पुत्रनिर्जितं। पतिलोकानहं पुण्यान्

कामये तपसा विभो। श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः। तपसा शोषयिष्यामि युधिष्ठिर कलेवरं। निवर्त्तस्व
कुरुश्रेष्ठ भीमसेनादिभिः सह। धर्मे ते धीयतां बुद्धिर्मनस्ते महदस्तु च॥ ॥इत्याश्रमवासिके १८॥ ॥वैशं॰॥ ॥कुंत्या
स्तु वचनं श्रुत्वा पांडवा राजसत्तम। व्रीडिताः संन्यवर्त्तंत पांचाल्यासहितानघाः। ततः शब्दो महानेव सर्वेषामभ
वत्तदा। अंतःपुराणां रुदतां दृष्ट्वा कुंतीं तथागतां। प्रदक्षिणमुपावृत्य राजानं पांडवास्तदा। अभिवाद्य न्यवर्त्तंत पृ
थां तामनिवृत्य वै। ततोऽब्रवीन्महातेजा धृतराष्ट्रोंबिकासुतः। गांधारीं विदुरं चैव समाभाष्याऽवगृह्य च। युधिष्ठिरस्य
जननी देवी साधु निवर्त्ततां। यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि। पुत्रैश्वर्यं महदिदमपहाय महाफलं। का नु गच्छे

द्दुर्गं पुत्रानुत्सृज्य मूढवत्। राज्यस्थया तपस्तप्तं दानं दत्तं कृतं व्रतं। अनया शक्यमेवाद्य श्रूयतां च वचो मम। गांधा
रि परितुष्टोस्मि वध्वाः शुश्रूषणेन वै। तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि। इत्युक्ता सौबलेयी तु राज्ञा कुंतीमु
वाच ह। तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत्। न च सा वनवासाय देवी कृतमतिस्तदा। शक्नोत्युपावर्त्तयितुं कुंतीं
धर्मपरां सतीं। तस्यास्तां तु स्थितिं ज्ञात्वा व्यवसायं कुरुस्त्रियः। निवृत्तांश्च कुरुश्रेष्ठान् दृष्ट्वा प्ररुरुदुस्तदा। उपावृ
त्तेषु पार्थेषु सर्वस्वेव वधूषु च। ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा। पांडवाश्चातिदीनास्ते दुःखशोकपरायणाः।
यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा। तदहृष्टमनानंदं गतोत्सवमिवाभवत्। नगरं हास्तिनपुरं सस्त्रीवृद्ध
कुमारकं। सर्वे चासन्निरुत्साहाः पांडवा जातमन्यवः। कुंत्या हीना सुदुःखार्त्ता वत्सा इव विनाकृताः। धृतराष्ट्र
स्तु तेनाह्ना गत्वा सुमहदंतरं। ततो भागीरथीतीरे निवासमकरोद्विभुः। प्रादुष्कृता यथान्यायमग्नयो वेदपार
गैः। व्यराजंत द्विजश्रेष्ठैस्तत्र तत्र तपोधनैः। प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः। स राजाग्नीन्पर्युपास्य

कृत्वा च विधिवत्तदा। संध्यागतं सहस्रांशुमुपातिष्ठत भारत। विदुरः संजयश्चैव राज्ञः शय्यां कुशैस्ततः। चक्रतुः कुरुवीरस्य गांधार्याश्चाविदूरतः। गांधार्याः संनिकर्षे च निषसाद कुशेषु च। युधिष्ठिरस्य जननी कुंती पृथ्व्रते स्थिता। तेषां संश्रवणे चापि निषेदुर्विदुरादयः। याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः। प्राधीतद्विजमुख्या सा संप्रज्वलितपावका। बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्द्धिनी। ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः। हुत्वाग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमं। उदङ्मुखा निरीक्षंत उपवासपरायणाः। सर्वेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि। शोचतां शोच्यमानानां पौरजानपदैर्जनैः॥ ॥इत्याश्रमवासिके १९॥ ॥वैशं॰॥ ॥ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते। निवासमकरोद्राजा विदुरस्य मते स्थितः। तत्रैनं पर्युपासंत ब्राह्मणा वनवासिनः। क्षत्रविट्शूद्रसंघाश्च बहवो भरतर्षभ। स तैः परिवृतो राजा कथाभिरभिनंद्य तान्। अनुजज्ञे सशिष्यांस्तु विधिवत्प्रतिपूज्य च। सायाह्ने स महीपालस्ततो गंगामुपेत्य वै। चकार विधिवच्छौचं गांधारी च यशस्विनी। तथैवान्ये पृथक् सर्वे तीर्थेष्वाप्लुत्य भारत। चक्रुः सर्वाः क्रियास्तत्र पुरुषा

विदुरादयः। कृतशौचं ततो वृद्धं श्वशुरं कुंतिभोजजा। गांधारी च पृथा राजन् गंगातीरमुपानयत्। राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः। सजुहाव ततो वह्निं नृपतिः सत्यसंगरः। ततो भागीरथीतीरात् कुरुक्षेत्रं जगाम सः। सानुगो नृपतिर्विद्वान्नियतः संयतेंद्रियः। तत्राश्रमपदं धीमानभिगम्य स पार्थिवः। आससादाथ राजर्षिं शातयूपं मनीषिणं। स हि राजा महानासीत्केकयेषु परंतपः। स पुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत्। तेनासौ सहितो राजा ययौ व्यासाश्रमं प्रति। तत्रैनं विधिवद्राजा प्रत्यगृह्णात्कुरूद्वहं। स दीक्षां तत्र संप्राप्य राजा कौरवनंदनः। शातयूपाश्रमे तस्मिन्निवासमकरोत्तदा। तस्मै सर्वं विधिं राज्ञे राजा चख्यौ महामतिः। आरण्यकं महाराज व्यासस्यानुमते मुनेः। एवं स तपसा जातो धृतराष्ट्रो महामनाः। योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा। तथैव देवी गांधारी वल्कलाजिनवासिनी। कुंत्या सह महाराज समानव्रतचारिणी। कर्मणा मनसा वाचा चक्षसा चैव ते नृप। संनियम्येंद्रियग्रामं आस्थिते परमं तपः। त्वगस्थिभूतः परिशुष्कमांसो जटाजिनी वल्कलसंवृतांगः। स पार्थिवस्तत्र तपश्चचार महर्षिवत्तीव्रमपेतमोहः। क्षत्ता च ध

भा॰आश्र॰
२२

मर्थविदग्र्यबुद्धिः स संजयस्तं नृपतिं सदारं। उपाचरद्घोरतपोजितात्मा तदा कृशो वल्कलचीरवासाः॥ ॥इत्याश्रम
वासिके २०॥ ॥वैशंपा॥ ॥ ततस्तत्र मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः। नारदः पर्वतश्चैव देवलश्च महातपाः। द्वैपा
यनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः। शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः। तेषां कुंती महाराज पूजां चक्रे
यथाविधि। ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया। तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः। रमयंतो महात्मानं
धृतराष्ट्रं जनाधिपं। कथांतरे च कस्मिंश्चिद्देवर्षिर्नारदस्तदा। कथामिमामकथयत्सर्वं प्रत्यक्षदर्शिवान्॥ नारदः॥
केकयाधिपतिः श्रीमान् राजासीदकुतोभयः। शतवैत्य इति ख्यातः शतयूपपितामहः। स पुत्रे राज्यमासज्य ज्येष्ठे प
रमधार्मिके। स शतवैत्यो धर्मात्मा प्रविवेश वनं नृपः। स गत्वा तपसः पारं दीप्तस्य वसुधाधिपः। पुरंदरसमं स्थानं प्र
तिपेदे महाद्युतिः। दृष्टपूर्वः स बहुशो राजन्संपतता मया। महेंद्रसदने राजा तपसा दग्धकिल्बिषः। तथा शैलालयो
राजा भगदत्तपितामहः। तपोबलेनैव नृपो महेंद्रसदनं गतः। तथा पृषध्रो नामासीद्राजा वज्रधरोपमः। स चापि
तपसा यातो नाकपृष्ठमितो नृपः। अस्मिन्नरण्ये नृपतिर्मांधातुरपि चात्मजः। पुरुकुत्सो नृपः सिद्धिं महतीं समवा

राम
२२

सहस्रचित्तो ४ सहस्रचित्य इत्युक्तः इति पाठः ५

प्तवान्। भार्या समभवत्तस्य नर्मदा सरितां वरा। सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः। शशलोमा च राजासी
द्राजन्परमधार्मिकः। सम्यगस्मिन्वने तप्त्वा ततो दिवमवाप्तवान्। द्वैपायनप्रसादाच्च त्वमपीदं तपोवनं। राज
न्नवाप्य दुःप्रापां गतिमग्र्यां गमिष्यसि। त्वं चापि राजशार्दूल तपसोंते श्रिया वृतः। गांधारीसहितो गंता गतिं ते
षां महात्मनां। पांडुः स्मरति ते भ्राता बलहंतुः समीपगः। त्वां सदैव महाराज श्रेयसा स च योक्ष्यति। तव शुश्रूषया
चैव गांधार्याश्च यशस्विनी। भर्तुः सलोकतामेषा गमिष्यति वधूस्तव। युधिष्ठिरस्य जननी स हि धर्मः सनात
नः। वयमेतत्प्रपश्यामो नृपते दिव्यचक्षुषा। प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरं। संजयस्तदनुध्यानादि
तः स्वर्गमवाप्स्यति॥ वैशंपा॥ एतच्छ्रुत्वा कौरवेंद्रो महात्मा सार्धं पत्न्या प्रीतिमान्संबभूव। विद्वान्वाक्यं नार
दस्य प्रशस्य चक्रे पूजां चातुलां नारदाय। ततः सर्वे नारदं विप्रसंघाः संपूजयामासुरतीव राजन्। राज्ञः प्री
त्या धृतराष्ट्रस्य ते वै पुनः पुनः संप्रहृष्टास्तदानीं॥ ॥इत्याश्रमवासिके २१॥ वैशंपा॥ ॥नारदस्य तु तद्वाक्यं प्रशं
सुर्द्विजसत्तमाः। शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत्। अहो भगवता श्रद्धा कुरुराजस्य वर्द्धिता। सर्वस्य

भा०आश्र०
२३

स्यजनस्यास्य ममैव च महाद्युते। अस्ति काचिद्विवक्षा तु तां मे निगदतः शृणु। धृतराष्ट्रं प्रति नृपं देवर्षे लोकपू
जितः। सर्ववृत्तांत तत्त्वज्ञो भवानृदिव्येन चक्षुषा। ऋक्षः पश्यति विप्रर्षे गतिर्या विविधा नृणां। उक्तवान्नृपती
नां च महेंद्रस्य सलोकतां। न त्वस्य नृपते र्लोकाः कथितास्ते महामुने। स्थानमप्यस्य नृपतेः श्रोतुमिच्छा
म्यहं विभो। त्वत्तः कीदृक्कदा चेति तन्मे माख्याहि तत्त्वतः। इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगं। व्याज
हार सभामध्ये दिव्यदर्शी महातपाः॥ ॥नारदः॥ ॥ यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिं। दृष्टवानस्मि रा
जर्षे तत्र पांडुं नराधिपं। सह माद्र्या महात्मानमिंद्रार्द्धासन संस्थितं। युधिष्ठिरेण स तु त्र कृतपुण्योप
बृंहितं। तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृपा। तपसो दुश्चरस्यास्य यदयं तप्यते तपः। तत्राहमिदमश्रौषं
शक्रस्य वदतः स्वयं। वर्षाणि त्रीणि शिष्टानि राज्ञोस्य परमायुषः। ततः कुबेरभवनं गांधारीसहितो नृपः। प्र
याता धृतराष्ट्रोयं राजराजाभिसत्कृतः। कामगेन विमानेन दिव्याभरणभूषितः। ऋषिपुत्रो महाभागस्तपसा
दग्धकिल्बिषः। संचरिष्यति लोकांश्च देवगंधर्वरक्षसां। स्वच्छंदेनेति धर्मात्मा यन्मां त्वमनुपृच्छसि। देवगुह्यमि

राम
२३

दं प्रीत्या मया वः कथितं महत्। भवंतो हि श्रुतधनास्तपसा दग्धकिल्बिषाः। सिद्धा भोजस्कृता चेयं पूर्वजन्मनि वि
श्रुता। पांडुनेव महाभागा रंस्यते शक्रसन्निधौ। इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः। सर्वेस्कमनसः प्रीता बभू ॥वै०॥२
वुः स च पार्थिवः। एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः। विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः॥ ॥इत्या
श्रमवासिके २२॥ ॥वैशं०॥ ॥ वनं गते कौरवेंद्रे दुःखशोकसमाहताः। बभूवुः पांडवा राजन् मातृशोकेन
चार्दिताः। तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपं। कुर्वाणाश्च कथां तत्र ब्राह्मणा नृपतिं प्रति। कथं नु
राजा वृद्धः सन् वने वसति निर्जने। गांधारी च महाभागा सा च कुंती कथं पृथा। सुखार्हः स च राजर्षिरसु
खं तद्वनं महत्। किमवस्थः समासाद्य प्रज्ञाचक्षुर्हतात्मजः। सुदुष्करं वसंत्येका कुंती पुत्रान् पश्यती। राज
श्रियं परित्यज्य वनवासमरोचयत्। विदुरः किमवस्थश्च भ्रातुः शुश्रूषुरात्मवान्। स च गावल्गणिर्धीमा
न् भर्तृपिंडानुपालकः। आकुमारं च पौरास्ते चिंताशोकसमाहताः। तत्र तत्र कथाश्चक्रुः समासाद्य पर
स्परं। पांडवाश्चैव ते सर्वे भृशं शोकपरायणाः। शोचंतो मातरं वृद्धां न्यूषुर्नातिचिरं पुरे। तथैव वृद्धं पितरं

हतपुत्रं जनेश्वरं। गांधारीं च महाभागां विदुरं च महामतिं। नैषां बभूव संप्रीतिस्तान्विचिंतयतां तदा। न राज्ये न च
नारीषु न वेदाध्ययनेषु च। परं निर्वेदमगमंश्चिंतयंतो नराधिपं। तं च ज्ञातिवधं घोरं संस्मरंतः पुनः पुनः। अ
भिमन्योश्च बालस्य विनाशं रणमूर्द्धनि। कर्णस्य च महाबाहोः संग्रामेष्वपलायिनः। तथैव द्रौपदेयानामन्ये
षां सुहृदामपि। वधं संस्मृत्य ते वीरा नातिप्रमनसो भवन्। हतप्रवीरां पृथिवीं हतरत्नां च भारत। सदैव चिंत
यंतस्ते न शमं चोपलेभिरे। द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी। नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टव
न्। वैराट्यास्तु तनयं दृष्ट्वा पितरं ते परीक्षितिं। धारयंस्मतु प्राणांस्तव पूर्वपितामहाः॥ ॥इत्याश्रमवासिके॥२३॥

॥ ॥वैशंपा॰॥ ॥ एवं ते पुरुषव्याघ्राः पांडवा मातृनंदनाः। स्मरंतो मातरं वीरा बभूवुर्भृशदुःखिताः। ते राजका
र्येषु पुरा व्यासक्ता नित्यशोऽभवन्। ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे। आविष्टा इव शोकेन नाभ्यनं
दंत कंचन। संभाष्यमाणा अपि ते न किंचित्प्रत्यपूजयन्। ते स्म वीरा दुराधर्षा गांभीर्ये सागरोपमाः। शोको
पहतविज्ञाना नष्टसंज्ञा इवाभवन्। अचिंतयंश्च जननीं ततस्ते पांडुनंदनाः। कथं नु वृद्धमिथुनं वहत्यद्य पृथा

कृशा। कथं च स महीपालो हतपुत्रो निराश्रयः। पत्न्या सह वसत्येको वने श्वापदसेविते। सा च देवी महाभागा गांधा
री हतबांधवा। पतिमंधं कथं वृद्धमन्वेति विजने वने। एवं तेषां कथयतामौत्सुक्यमभवत्तदा। गमने चाभवद्बुद्धि
र्धृतराष्ट्र दिदृक्षया। सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत्। अहो मे भवतो दृष्टं हृदयं गमनं प्रति। न हि त्वां
गौरवेणाहमशकं वक्तुमंजसा। गमनं प्रति राजेंद्र तदिदं समुपस्थितं। दिष्ट्या द्रक्ष्यामि तां कुंतीं वर्त्तयंतीं यशस्वि
नीं। जटिलां तापसीं वृद्धां कुशकाशपरिक्षतां। प्रासादहर्म्यसंवृद्धामत्यंतसुखभागिनीं। कदा नु जननीं श्रांतां
द्रक्ष्यामि भृशदुःखितां। अनित्याः खलु मर्त्यानां गतयो भरतर्षभ। कुंती राजसुता यत्र वसत्यसुखिता वने। सह
देववचः श्रुत्वा द्रौपदी योषितां वरा। उवाच देवी राजानमभिपूज्याभिनंद्य च। कदा द्रक्ष्यामि तां देवीं यदि जीवति
सा पृथा। जीवंत्या ह्यद्य नः प्रीतिर्भविष्यति जनाधिप। एषा तेऽस्तु मतिर्नित्यं धर्मे रमतां मनः। योद्यत्वमस्मान्
राजेंद्र श्रेयसा योजयिष्यसि। अग्रपादस्थितं चेमं विद्धि राजन्वधूजनं। कांक्षंतं दर्शनं कुंत्या गांधार्याः श्वशुर
स्य च। इत्युक्तः स नृपो देव्या द्रौपद्या भरतर्षभ। सेनाध्यक्षान्समानाय्य सर्वानिदमुवाच ह। निर्यापयत मे सेनां

भा० आश्र०
२५

प्रभूतरथकुंजरां। द्रष्टुमिच्छामि वनसंस्थं च धृतराष्ट्रं महीपतिं॥ अध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे। सज्जी
क्रियंतां सर्वाणि शिबिकाश्च सहस्रशः॥ शकटापणवेशाश्च कोशाः शिल्पिन एव च। निर्यांतु कोशपालाश्च कुरुक्षे
त्राश्रमं प्रति। यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवं। अनावृतः सुविहितः स यातु सुरक्षितः॥ सूदाः पौरोगवाश्चैव
सर्वं चैव महानसं। विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम। प्रयाणं घुष्यतां चैव श्वोभूत इति मा चिरं। क्रियतां पथि वा
प्यद्य वेश्मानि विविधानि च। एवमाज्ञाप्य राजासौ भ्रातृभिः सह पांडवः॥ श्वोभूते निर्ययौ राजन् सस्त्रीवृद्धपुरःसरः॥
स बहिर्दिवसानेवं जनौघं परिपालयन्। न्यवसन्नृपतिः पंच ततो गच्छद्वनं प्रति॥ ॥इत्याश्रमवासिके २४॥ ॥
॥ ॥वैशंपा॥ आज्ञापयामास ततः सेनां भरतसत्तमः। अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः॥ योगो योग इति
प्रीत्या ततः शब्दो महानभूत्। क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति॥ केचिद्यानैर्नरा जग्मुः केचिदश्वैर्मनोज
वैः। कांचनैश्च रथैः केचित्ज्वलितज्वलनोपमैः॥ गजेंद्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप। पदातयस्तथैवान्ये नखर
प्रासयोधिनः॥ पौरजानपदाश्चैव यानैर्बहुविधैस्तथा। अन्वयुः कुरुराजानं धृतराष्ट्रदिदृक्षया। स चापि राजवच

राम
२५

नाद्राचार्यो गौतमः कृपः। सेनामादाय सेनानीः प्रययावाश्रमं प्रति। ततो द्विजैः परिवृतः कुरुराजो युधिष्ठिरः॥ संस्तूय
मानो बहुभिः सूतमागधबंदिभिः। पांडुरेणातपत्रेण ध्रियमाणेन मूर्द्धनि॥ रथानीकेन महता निर्जगाम कुरूद्वहः।
गजैश्चाचलसंकाशैर्भीमकर्मा वृकोदरः॥ सज्जयंत्रायुधोपेतः प्रययौ पवनात्मजः। माद्रीपुत्रावपि तथा हयारो
हौ सुसंवृतौ॥ जग्मतुः शीघ्रजवनौ सन्नद्धकवचध्वजौ। अर्जुनश्च महातेजा रथेनादित्यवर्चसा॥ वशी श्वेतैर्हयैर्दिव्यै
र्युक्तेनान्वगमन्नृपं। द्रौपदीप्रमुखाश्चैव स्त्रीसंघाः शिबिकागताः॥ स्त्र्यध्यक्षगुप्ताः प्रययुर्विसृजंत्योऽमितं वसु।
समृद्धरथहस्त्यश्वं वेणुवीणानुनादितं॥ शुशुभे पांडवं सैन्यं तत्तदा भरतर्षभ। नदीतीरेषु रम्येषु सरःसु च विशां
पते। वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुंगवाः॥ युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः। युधिष्ठिरस्य वच
नात् पुरगुप्तिं प्रचक्रतुः॥ ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत्। क्रमेणोत्तीर्य यमुनां नदीं परमपावनीं॥ स
ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः। शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह। ततः प्रमुदितः सर्वो जनस्तद्वनमं
जसा। विवेश सुमहानादैरापूर्य भरतर्षभ॥ ॥इत्याश्रमवासिके २५॥ वैशं॥ ॥ ततस्ते पांडवा दूरादवतीर्य पदात

यः अभिजग्मुर्नरपते राश्रमं विनयानताः॥ सचयो धजनः सर्वे ये चराष्ट्रनिवासिनः॥ स्त्रियश्च कुरुमुख्यानां पद्भिरे
वान्वयुस्तदा॥ आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पांडवाः॥ दूरत्वं मृगगणाकीर्णं कदलीवनशोभितं॥ ततस्तत्र समाज
ग्मुस्तापसा नियतव्रताः॥ पांडवानागतान्द्रष्टुं कौतूहलसमन्विताः॥ तानपृच्छन्ततो राजा क्वासौ कौरववंशभृत्॥
पिताज्येष्ठो गतोस्माकमिति बाष्पपरिप्लुतः॥ ते तमूचुस्ततो वाक्यं यमुनामवगाहितुं॥ पुष्पाणामुदकुंभस्य चा
र्थे गतइति प्रभो॥ तैराख्यातेन मार्गेण ततस्ते जग्मुरंजसा॥ ददृशुस्ते विदूरेतान्सर्वानथ पदातयः॥ ततस्ते स
त्वरा जग्मुः पितुर्दर्शनकांक्षिणः॥ सहदेवस्तु वेगेन प्राधावद्यत्र सा पृथा॥ सस्वरं रुरुदे धीमान्मातुः पादावु
पस्पृशन्॥ सा च बाष्पाकुलमुखी ददर्श दयितं सुतं॥ बाहुभ्यां संपरिष्वज्य समुन्नाम्य च पुत्रकं॥ गांधार्याः
कथयामास सहदेवमुपस्थितं॥ अनंतरं च राजानं भीमसेनमथार्जुनं॥ नकुलं च पृथा दृष्ट्वा त्वरमाणोपच
क्रमे॥ सा ह्यग्रे गच्छति तयोर्दंपत्योर्हतपुत्रयोः॥ कर्षंती तौ ततस्ते तान्दृष्ट्वा संन्यपतन्भुवि॥ राजा तान्स्वरयोगेन
स्पर्शनेन च महामनाः॥ प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः॥ ततस्ते बाष्पमुत्सृज्य गांधारीसहितं नृप॥

उपतस्थुर्महात्मानो मातरं च यथाविधि॥ सर्वेषां तोयकलशान्जगृहुस्ते स्वयं तदा॥ पांडवा लब्धसंज्ञास्ते मात्रा चा
श्वासिताः पुनः॥ तथा नार्यो नृसिंहानां सचयोधजनस्तदा॥ पौरजानपदाश्चैव ददृशुस्तं जनाधिपं॥ निवेदया
मास तदा जनं तन्नामगोत्रतः॥ युधिष्ठिरो नरपतिः स चैनं प्रत्यपूजयत्॥ स तैः परिवृतो मेने हर्षबाष्पाकु
लेक्षणः॥ राजात्मानं गृहगतं पुरे च गजसाह्वये॥ अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः॥ गांधार्या स
हितो धीमान्कुंत्या च प्रत्यनंदत॥ ततश्चाश्रममागच्छत्सिद्धचारणसेवितं॥ दिदृक्षुभिः समाकीर्णं नभस्ता
रागणैरिव॥ ॥इत्याश्रमवासिके द्वाविंशः॥ ॥ स तैः सह नरव्याघ्रैर्भ्रातृभिर्भरतर्षभ॥ राजा रुचिरपद्माक्षैरासां
चक्रे तदाश्रमे॥ तापसैश्च महाभागैर्नानादेशसमागतैः॥ द्रष्टुं कुरुपतेः पुत्रान्पांडवान्पृथुवक्षसः॥ तेऽब्रुवन्
ज्ञातुमिच्छामः कतरोऽत्र युधिष्ठिरः॥ भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी॥ तानाचख्यौ तदा सूतः सर्वा
न्नामाभिनामतः॥ संजयो द्रौपदीं चैव सर्वाश्चान्याः कुरुस्त्रियः॥ ॥संजय उवाच॥ ॥ य एष जांबूनदशुद्धगौ
रतनुर्महासिंह इव प्रदीप्तः॥ प्रचंडघोणः पृथुदीर्घनेत्रस्ताम्रायताक्षः कुरुराज एषः॥ अयं पुनर्मत्तगजेंद्रगा

भा·आश्र०
२७

मीप्रतप्तचामीकरशुद्धगौरः। एष्ठ्यायतांसः पृथुदीर्घबाहुर्वृकोदरः पश्यत पश्यतेनं। यस्त्वेष पार्श्वेस्य महाधनु
श्चान् श्यामो युवा वारणयूथपाभः। सिंहोन्नतांसो गजखेलगामी पद्मायताक्षो र्जुनएषवीरः। कुंतीसमीपे पु
रुषोत्तमौ तु यमाविमौ विष्णुमहेंद्रकल्पौ। मनुष्यलोके सकले समोस्ति ययोर्न रूपे न कुले न शीले। इयं पुनः
पद्मदलायताक्षी मध्यं वयः किंचिदिव स्पृशंती। नीलोत्पलाभा पुरदेवतेव कृष्णा स्थिता मूर्त्तिमती व लक्ष्मीः।
अस्यास्तु पार्श्वे कनकोत्तमाभा दिविप्रभा मूर्त्तिमयीव सौरी। मध्ये स्थिते षां भगिनी द्विजाग्र्या श्चक्रायुधस्या
प्रतिमस्य तस्य। इयं च जांबूनदशुद्धगौरी पार्थस्य भार्या भुजगेंद्रकन्या। चित्रांगदा चैव नरेंद्रकन्या येषा स
वर्णाग्र्यमधूकपुष्पैः। इयं स्वसा राजचमूपतेश्च प्रबुद्धनीलोत्पलदामवर्णा। पस्पर्द्ध कृष्णेन सदा नृपो यो
वृकोदरस्यैष परिग्रहोग्र्यः। इयं तु राज्ञो मगधाधिपस्य सुता जरासंध इति श्रुतस्य। यवीयसो माद्रवतीसुत
स्य भार्या मता चंपकदामगौरी। इंदीवरश्यामतनुः स्थिता तु येषा परा सन्न महीतले च। भार्या मता माद्रवती
सुतस्य ज्येष्ठस्य सेयं कमलायताक्षी। इयं तु निष्टप्तसुवर्णगौरी राज्ञो विराटस्य सुतासपुत्रा। भार्याभिमन्यो

राम
२७

र्निहतो रणे यो द्रोणादिभिस्तैर्विरथो रथस्थैः। एतास्तु सीमंतशिरोरुहा याः शुक्लोत्तरीया नरराजपत्न्यः। राज्ञोस्य वृद्धस्य
परः शतारव्याः स्नुषा नृवीरा हतपुत्रनाथाः। एता यथामुख्यमुदाहृता वो ब्राह्मण्यभावादृजुबुद्धिसत्वाः। सर्वा भव
द्भिः परिपृछिता या नरेंद्रपत्न्यः सुविशुद्धसत्वाः॥ ॥वैशंपा॥ ॥एवं स राजा कुरुवर्यवृद्धः समागतस्तैर्नरदेवपुत्रैः।
पप्रछ सर्वान् कुशलं तदानीं गतेषु सर्वेष्वथ तापसेषु। योधेषु चाप्याश्रममंडलं तन् मुक्त्वा निविष्टेषु विमुच्य पत्रं।
स्त्रीवृद्धबाले च सुसन्निविष्टे यथार्हतस्तान् कुशलान्यपृछत्॥ ॥इत्याश्रमवासिके २७॥ धृतराष्ट्रः॥ ॥युधिष्ठिर
महाबाहो कच्चित्त्वं कुशली ह्यसि। सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा। ये च त्वामनुजीवंति कच्चित्ते पि नि
रामयाः। सचिवा भृत्यवर्गाश्च गुरवश्चैव ते नृप। कच्चिद्वर्त्तसि पौराणीं वृत्तिं राजर्षिसेवितां। कच्चिन्न्यायाननु
छिद्य कोशस्ते भिप्रपूर्यते। अरिमध्यस्थमित्रेषु वर्त्तसे चानुरूपतः। ब्राह्मणानग्रहारै र्वा यथावदनुपश्यसि। कच्चि
त्ते परितुष्यंति शीलेन भरतर्षभ। शत्रवो गुरवः पौरा भृत्या श्च स्वजनोपि वा। कच्चिद्यजसि राजेंद्र श्रद्धावान्पितृदे
वताः। अतिथीनन्नपानेन कच्चिदर्चसि भारत। कच्चिच्च विषये विप्राः स्वकर्मनिरतास्तव। क्षत्रिया वैश्यवर्गा वा

वाहान्

भा०आ०श्र०
२८

शूद्राश्चापि कुटुंबिनः। कच्चिदाबालवृद्धं ते न शोचति न याचते। यामयः पूजिताः कच्चित्तव गेहे नरर्षभ। कच्चिद्राज
र्षिचिंत्रोयं त्वामासाद्य महीपतिं। यथोचितं महाराज यत्रासा नावसीदति॥ ॥वैशंपा॥ ॥इत्येवं वादिनं तं सन्या
यवित् प्रत्यभाषत। कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि॥ ॥युधिष्ठिर उ०॥ ॥कच्चित्ते वर्द्धते राजन् तपो
मंदश्रमश्च ते। अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा। अप्यस्याः सफलो राजन् वनवासो भविष्यति।
इयं च माता ज्येष्ठा मे शीतवाताध्वकर्षिता। घोरेण तपसा युक्ता देवी कच्चिन्न शोचति। हतान्पुत्रान् महावीर्या
न् क्षत्रधर्मपरायणान्। नापध्यायति वा कच्चिदस्मान्पापकृतः सदा। क्व चासौ विदुरो राजन्नेनं पश्यामहे
वयं। संजयः कुशली चायं कच्चिन्नु तपसि स्थितः॥ ॥वैशंपा॥ ॥इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपं। कुश
ली विदुरः पुत्र तपो घोरं समाश्रितः। वायुभक्षो निराहारः कृशो धमनिसंततः। कदाचिद्दृश्यते विप्रैः शून्येस्मि
न्कानने क्वचित्। एवं तु वदतस्तस्य धृतराष्ट्रस्य धीमतः। जगाम स वनं राजन्धर्मराजो युधिष्ठिरः। यत्रास्ते वि
दुरः पुण्या जटी वायमुखः कृशः। दिग्वासा मलदिग्धांगो वनरेणुसमुक्षितः। दूरादालक्षितः क्षत्ता तत्राख्यातो

राम
२८

महीपतेः। निवर्त्तमानः सहसा जनं दृष्ट्वाश्रमं प्रति। तमन्वधावन्नृपतिरेक एव युधिष्ठिरः। प्रविशंतं वनं घोरं ल
क्ष्यालक्ष्यं क्वचित् क्वचित्। भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः। इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत। ततो
विविक्त एकांते तस्थौ बुद्धिमतां वरः। विदुरो वृक्षमाश्रित्य कंचित्तत्र वनांतरे। तं राजा क्षीणभूयिष्ठमाकृतीमा
त्रसूचितं। अभिजज्ञे महाबुद्धिं महाबुद्धिर्यु धिष्ठिरः। युधिष्ठिरोहमस्मीति वाक्यमुक्त्वाग्रतः स्थितः। विदुर
श्चापि वै राजा तं च प्रत्यभ्यपूजयन्। ततः सोनिमिषो भूत्वा राजानं तमुदैक्षत। संयोज्य विदुरस्तस्मिन् दृष्टिं दृ
ष्ट्या समाहितः। विदुरोवेशविदुरो गात्रैर्गात्राणि चैव हि। प्राणान्प्राणेषु विदधदिंद्रियाणींद्रियेषु च। सयोग
बलमास्थाय विवेश नृपतेस्तनुं। विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव। विदुरस्य शरीरं तु तथैव स्तब्ध
लोचनं। वृक्षाश्रितं तदा राजा ददर्शगतलोचनं। बलवंतं तथात्मानं मेने बहुगुणं तदा। धर्मराजो महा
तेजास्तच्च सस्मार पांडवः। पौराणमात्मनः सर्वं विद्यावान्स विशांपते। योगधर्मं महातेजा व्यासेन कथि
तं यथा। धर्मराजस्तु तत्रैनं संचिस्कारयिषुस्तदा। दग्धुकामोभवद्विद्वानथ वागभ्यभाषत। भो भो राजन्द

भा· आश्र·
९

न्नदग्धव्यमेतद्विदुरसंज्ञकं। कलेवरमिहैवं ते धर्म एष सनातनः। लोकाः संतानका नाम भविष्यंत्यस्य भारत।
यतिधर्ममवाप्तो सौ नैष शोच्यः परंतप। इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः। राज्ञो वै चित्रवीर्यस्य तत्स
र्वं प्रत्यवेदयत्। ततः स राजा द्युतिमान् स च सर्वो जनस्तदा। भीमसेनादयश्चैव परं विस्मयमागताः। तच्छ्रु
त्वा प्रीतिमान् राजा भूत्वा धर्मजमब्रवीत्। आपो मूलं फलं चैव ममेदं प्रतिगृह्यतां। यदन्नो हि नरो राजं
स्तदन्नोस्यातिथिः स्मृतः। इत्युक्तः स तथेत्येवं प्राह धर्मात्मजो नृपं। फलं मूलं च बुभुजे राज्ञा दत्तं सहानु
जः। ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः। तां रात्रिमवसन् सर्वे फलमूलजलाशनाः॥ ॥इत्याश्रमवासिके॥
२८॥ ॥वैशाम्॥ ॥ततस्तु राजन् सर्वेषामाश्रमे पुण्यकर्मणां। शिवा नक्षत्रसंपन्ना सा व्यतीयाय शर्वरी।
ततस्तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः। विचित्रपदसंचारा नानाश्रुतिभिरन्विताः। पांडवास्त्वभितो मा
तुर्धरण्यां सुषुपुस्तदा। उत्सृज्य सुमहार्हाणि शयनानि नराधिप। यदाहारो भवद्राजा धृतराष्ट्रो महामनाः।
तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा। व्यतीतायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियः। भ्रातृभिः सहितो रा

राम
२९

जा ददर्शाश्रममंडलं। सांतःपुरपरीवारः सभृत्यः सपुरोहितः। यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया। दद
र्श तत्र वेदीं च संप्रज्वलितपावकां। कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थितां। वानेयपुष्पनिकरै राज्यधू
मोद्गमैरपि। ब्राह्मेण तपसा युक्तां युक्तां मुनिगणस्य ताः। मृगयूथैरनुद्विग्नैस्तत्र तत्र समाश्रितैः। अशं
कितैः पक्षिगणैः प्रगीतैरिव च प्रभो। केकाभिर्नीलकंठानां दात्यूहानां च कूजितैः। कोकिलानां च कुहरैः
सुखैः श्रुतिमनोहरैः। प्राधीतद्विज घोषैश्च क्वचित्क्वचिदलंकृतां। फलमूलसमृद्धाभिर्महद्भिश्चो
पशोभितां। ततः स राजा प्रददौ तापसार्थमुपाहृतान्। कलशान् कांचनान्राजन् तथैवोदुंबरानपि।
अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः। कमंडलूंश्च स्थालीश्च पिठराणि च भारत। भाजनानि च लौहा
नि पात्रीश्च विविधान्नृपः। यद्यदिच्छति यावच्च यच्चान्यदपि भारत। एवं स राजा धर्मात्मा परीत्याश्रममंडलं।
वसु विश्रं च तत्सर्वं पुनरायान्महीपतिः। कृताह्निकं च राजानं धृतराष्ट्रं महीपतिं। ददर्शासीनमव्यग्रं गां
धारीसहितं तदा। मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थितां। कुंतीं ददर्श धर्मात्मा शिष्टाचारसमन्वितां।

भा॰ आश्र॰
२०

स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः ॥ निर्दिष्टमभ्यनुज्ञातो बृस्यामुपविवेश ह ॥ भीमसेनादयश्चै
व पांडवा भरतर्षभ ॥ अभिवाद्योपसंगृह्य निषेदुः पार्थिवाज्ञया ॥ स तैः परिवृतो राजा शुशुभेतीव कौरवः ॥ बि
भ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः ॥ तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः ॥ शतयूपप्रभृतयः कु
रुक्षेत्रनिवासिनः ॥ व्यासश्च भगवान्विप्रो देवर्षिगणसेवितः ॥ वृतः शिष्यैर्महातेजा दर्शयामास पार्थि
वं ॥ ततः स राजा कौरव्यः कुंतीपुत्रश्च वीर्यवान् ॥ भीमसेनादयश्चैव प्रत्युत्थायाभ्यवादयन् ॥ समागत
स्ततो व्यासः शतयूपादिभिर्वृतः ॥ धृतराष्ट्रं महीपालमास्यतामित्यभाषत ॥ स वर्णं विष्टरं कौशं कृष्णाजि
नकुशोत्तरं ॥ प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितं ॥ ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समंततः ॥ द्वैपायना
भ्यनुज्ञाता निषेदुर्विपुलौजसः ॥ ॥ इत्याश्रमवासिके २९ ॥ ॥ वैशंपा॥ ॥ ततः समुपविष्टेषु पांडवेषु महा
त्मसु ॥ व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ॥ धृतराष्ट्र महाबाहो कच्चित्ते वर्त्तते तपः ॥ कच्चिन्मनस्ते
प्रीणाति वनवासे नराधिप ॥ कच्चित्हृदि न ते शोको राजन्पुत्रविनाशजः ॥ कच्चिज्ज्ञानानि सर्वाणि सुप्र

शातातप

राम
२०

सन्नानि ते नघ ॥ कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिं ॥ कच्चिद्वधूश्च गांधारी न शोकेनाभिभूयते ॥ महा
प्राज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी ॥ आगमापायतत्वज्ञा कच्चिदेषा न शोचति ॥ कच्चित्कुंती च राजंस्त्वां शुश्रू
षुरनहंकृता ॥ या परित्यज्य स्वं पुत्रं गुरुशुश्रूषणे रता ॥ कच्चिद्धर्मसुतो राजा महात्मा स महामनाः ॥ भीमार्जुनयमा
श्चैव कच्चिदेतेपि सांत्विताः ॥ कच्चिन्नंदसि दृष्ट्वैतान्कच्चित्ते निर्मलं मनः ॥ कच्चिच्छुद्धभावोसि जातज्ञानो नराधि
प ॥ एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत ॥ निर्वैरता महाराज सत्यमक्रोध एव च ॥ कच्चिन्न ते व तापोस्ति वनवासे
न भारत ॥ स्वादु से वन्यमन्नं वा उपवासोपि वा भवेत् ॥ विदितं चापि राजेंद्र विदुरस्य महात्मनः ॥ गमनं विधियातेन
धर्मस्य सुमहात्मनः ॥ मांडव्यशापाद्धि स वै धर्मो विदुरतां गतः ॥ महाबुद्धिर्महायोगी महात्मा सुमहामनाः ॥
बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु च ॥ न तथा बुद्धिसंपन्नो यथा स पुरुषर्षभः ॥ तपोबलव्ययं कृत्वा सु
चिरात्संभृतं तदा ॥ मांडव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः ॥ नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च ॥
वीर्य॰ वैचित्रक्षेत्रे स जातः सुमहामतिः ॥ भ्राता तव महाराज देवदेवः सनातनः ॥ धारणात्मनसो ध्यानाद्यं

धर्मं कियथोविदुः। सत्येन संवर्द्धयितिदमेननियमेन च। अहिंसयाचदानेन तप्यमानः सनातनः। येनयोग
बलाज्जातः कुरुराजो युधिष्ठिरः। धर्मइत्येष नृपते प्राज्ञेनामितबुद्धिना। यथावह्निर्यथा वायुर्यथापः पृथि
वीयथा। यथाकाशंतथा धर्मइहवामुत्रचस्थितः। सर्वगश्चैव राजेंद्र सर्वंव्याप्य चराचरं। दृश्यते देवदेवैः सत्सि
द्धैर्निर्मुक्तकल्मषैः। योहिधर्मः सविदुरो विदुरोयः सपांडवः। सएवराजन्दृश्यस्ते पांडवप्रेष्यवत्स्थितः। प्रवि
ष्टः सस्वमात्मानं भ्राताते बुद्धिसत्तमः। दिष्ट्या महात्मा कौंतेयो महायोगबलान्वितः। त्वांचापिश्रेयसायो
ज्यनचिराद्भरतर्षभ। संशयच्छेदनार्थाय प्राप्तं मां विद्धि पुत्रक। नकृतं यत्पुराकैश्चित्कर्मलोके महर्षिभिः।
आश्चर्यभूतं तपसः फलं तद्दर्शयामिवः। किमिच्छसि महीपाल मत्तः प्राप्तुमभीप्सितं। द्रष्टुं प्रष्टुमथश्रोतुं त
त्कर्तास्मितवानघ॥ ॥इत्याश्रमवासिके २० ॥जनमेजयः॥ वनवासगते विप्र धृतराष्ट्रे महीपतौ। सभार्ये नृ
पशार्दूलेवध्वा कुंत्या समन्विते। विदुरे चापिसंसिद्धे धर्मराजव्यपाश्रिते। वसत्सु पांडुपुत्रेषु सर्वेष्वाश्र
ममंडले। यत्तदाश्चर्यमितिवै करिष्यामीत्युवाच ह। व्यासः परमतेजस्वी महर्षिस्तद्वदस्वमे। वनवासे चकौ

रव्यः कियंतं कालमच्युतः। युधिष्ठिरो नरपतिर्न्यवसत्सजनस्तदा। किमाहाराश्चतेतत्र ससैन्यान्यवसन्प्रभो। सां
तःपुरा महात्मान इतितद्ब्रूहिमेनघ॥ ॥वैशंपा० ॥तेनुज्ञातास्तदाराजन्कुरुराजेनपांडवाः। विविधान्यन्नपा
नानि विश्राम्यानुभवंतिते। मासमेकं विजह्रुस्ते ससैन्यांतःपुरा वने। अथतत्रागमद्व्यासो यथोक्तं तेमया
नघ। तथाचतेषां सर्वेषां कथाभिर्नृपसंनिधौ। व्यासमन्वासतां राजन्नाजग्मुर्मुनयोपरे। नारदः पर्व
तश्चैव देवलश्च महातपाः। विश्वावसुस्तुंबरुश्च चित्रसेनश्च भारत। तेषामपि यथान्यायं पूजां चक्रे म
हामनाः। धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः। निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात्। आसने
ष्वथ पुण्येषु बर्हिष्केषु वनेषु च। तेषु तत्रोपविष्टेषु सतु राजा महीपतिः। पांडुपुत्रैः परिवृतो निषसाद कुरूद्व
हः। गांधारीचैव कुंती च द्रौपदी सात्वती तथा। स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः। तेषांत
त्रकथा दिव्या धर्मिष्ठाश्चाभवन्नृप। ऋषीणां च पुराणानां देवासुरविमिश्रिताः। ततः कथांते व्यास
स्तं प्रज्ञाचक्षुषमीश्वरं। प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः। प्रीयमाणो महातेजाः सर्ववेदविदां वरः।

भा॰आश्र॰
३२

विदितं मम राजेंद्र यत्ते हृदि विवक्षितं। दह्यमानस्य शोकेन तव पुत्रकृतेन वै। गांधार्याश्चैव यद्दुःखं हृदि तिष्ठति
नित्यदा। कुंत्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितं। यच्च धारयते तीव्रं दुःखं पुत्रविनाशजं। सुभद्रा कृष्णभगिनी त
च्चापि विदितं मम। श्रुत्वा समागममिदं सर्वेषां वस्तपोन्नृप। संशयच्छेदनार्थाय प्राप्तः कौरवनंदन। इमे च देवगं
धर्वाः सर्वे चेमे महर्षयः। पश्यंतु तपसो वीर्यमद्य मे चिरसंचितं। तदुच्यतां महाबाहो कं कामं प्रददामि ते। प्रव
णोस्मि वरं दातुं पश्य मे तपसः फलं। एवमुक्तः स राजेंद्रो व्यासेनामितबुद्धिना। स मुहूर्त्तमिव संचिंत्य वचनायो
पचक्रमे। धन्योस्म्यनुगृहीतश्च सफलं जीवितं च मे। यन्मे समागमोद्येह भवद्भिः सह साधुभिः। अद्य चाप्यवग
च्छामि गतिमिष्टामिहात्मनः। ब्रह्मकल्पैर्भवद्भिश्च समेतोहं तपोधनाः। दर्शनादेव भवतां पूतोहं नात्र संश
यः। विद्यते न भयं किंचित्परलोके ममानघा। किंतु तस्य सुदुर्बुद्धेर्मंदस्यापनयैर्भृशं। दूयते मे मनो नित्यं शोच
तः पुत्रगृद्धिनः। अपापाः पांडवा येन निकृताः पापबुद्धिना। घातिता पृथिवी येन सहयाः सनरद्विपा। राजानश्च
महात्मानो नानाजनपदेश्वराः। आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः। ये ते पितॄंश्च दारांश्च प्राणांश्च मनसः

राम
३२

प्रियान्। परित्यज्य गताः शूराः प्रेतराजनिवेशनं। का नु तेषां गतिर्ब्रह्मन् मित्रार्थे ये हता मृधे। तथैव पुत्रपौ
त्राणां मम ये निहता युधि। दूयते मे मनोभीक्ष्णं घातयित्वा महाबलं। भीष्मं शांतनवं वृद्धं द्रोणं च द्विजसत्त
मं। मम पुत्रेण मूढेन पापेन सुहृद्द्विषा। क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता। एतत्सर्वमनुस्मृत्य दह्य
मानो दिवानिशं। न शांतिमधिगच्छामि दुःखशोकसमाहतः। इति मे चिंतयानस्य पितः शांतिर्न विद्यते।
॥ ॥वैशाम्॥ ॥ तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितं। पुनर्नवीकृतः शोको गांधार्या जनमेजय। कुंत्या
द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च। तासां च वरनारीणां वधूनां कौरवस्य ह। पुत्रशोकसमाविष्टा गांधा
री त्विदमब्रवीत्। श्वशुरं बद्धनयना देवी प्रांजलिरुत्थिता। षोडशेमानि वर्षाणि गतानि मुनिपुंगव। अस्य
राज्ञो हतान्पुत्रान् शोचतो न शमोस्ति वै। पुत्रशोकसमाविष्टो निश्वसन्नेष भूमिपः। न शेते वसतीः स
र्वा धृतराष्ट्रो महामुने। लोकानन्यान् समर्थोसि स्रष्टुं सर्वं तपोबलात्। किं मे लोकांतरगतान् राज्ञो दर्शयि
तुं सुतान्। इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशं। शोचत्यतीव साध्वी ते स्नुषाणां दयिता स्नुषा। तथा

कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी। सौभद्रवधसंतप्ता भर्त्रांशोचति भामिनी॥ इयं च भूरिश्रवसो भार्या परम
संमता। भर्तृव्यसनशोकार्त्ता भर्त्रांशोचति भामिनी॥ यस्यास्तु श्वशुरो धीमान् बाह्लीकः स कुरूद्वहः॥ निहतः
सोमदत्तश्च पित्रा सह महारणे। श्रीमतोस्य महाबुद्धेः संग्रामेष्वपलायिनः॥ पुत्रस्यैते पुत्रशतं निहतं यद्
रणाजिरे। तस्य भार्याशतमिदं दुःखशोकसमाहतं॥ पुनः पुनर्वर्द्धयानं शोकं राज्ञो ममैव च॥ अनारंभेण
महता मामुपास्ते महामुने॥ ये च शूरा महात्मानः श्वशुरा मे महारथाः॥ सोमदत्तप्रभृतयः का नु तेषां गतिः
प्रभो॥ तव प्रसादाद्भगवन् विशोकोयं महीपतिः॥ यथा स्याद्भविता चाहं कुंती चैषा वधूस्तव॥ इत्युक्तवत्यां
गांधार्यां कुंती व्रतपरायणा॥ प्रछन्नजातं पुत्रं तं सस्मारादित्यसंभवं॥ तामृषिर्वरदो व्यासो दूरश्रवणदर्शि
नः॥ अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः॥ तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितं॥ तद्ब्रूहि त्वं महाभागे
यत्ते मनसि वर्त्तते॥ श्वशुराय ततः कुंती प्रणम्य शिरसा तदा॥ उवाच वाक्यं सव्रीडा विवृण्वाना पुरातनं॥ ॥
॥ ॥ इत्याश्रमवासिके २९॥ ॥ कुंत्युवाच॥ ॥ भगवन् श्वशुरो मेसि दैवतस्यापि दैवतं॥ स मे देवाधिदेवस्त्वं

शृणु सत्यां गिरं मम॥ तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः॥ भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयं॥ शौचेन त्वा
गसस्त्यागैः शुद्धेन मनसा तथा॥ कोपस्थानेष्वपि महत्स्वकुप्यन्न कदाचन॥ स प्रीतो वरदो मे भूत्कृतकृत्यो महा
मुनिः॥ अवश्यं ते गृहीतव्यमिति मां सोब्रवीद्वचः॥ ततः शापभयाद्विप्रमवोचं पुनरेव तं॥ एवमस्त्विति च प्राह पु
नरेव स मे द्विजः॥ धर्मस्य जननी भद्रे भवित्री त्वं शुभानने॥ वशे स्थास्यंति ते देवा यांस्त्वमावाहयिष्यसि॥ इ
त्युक्त्वांतर्हितो विप्रस्ततोहं विस्मिताभवं॥ न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति॥ अथ हर्म्यतलस्थाहं रविमु
द्यंतमीक्षती॥ संस्मृत्य तदृषेर्वाक्यं स्पृहयंती दिवाकरं॥ स्थिताहं बालभावेन तत्र दोषमबुध्यती॥ अथ देवः सहस्रां
शुर्मत्समीपगतोभवत्॥ द्विधा कृत्वात्मनो देहं भूमौ च गगनेपि च॥ ततापलोकानेकेन द्वितीयेनागमच्च मां॥
स मामुवाच वेपंतीं वरं मत्तो वृणीष्वह॥ गम्यतामिति तं चाहं प्रणम्य शिरसावदं॥ स मामुवाच तिग्मांशुर्वृथा
ह्वानं न मे क्षमं॥ धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव॥ तमहं रक्षती विप्रं शापादनपकारिणं॥ पुत्रो मे त्वत्समो
देव भवेदिति ततो ब्रुवं॥ ततो मां तेजसाविश्य मोहयित्वा च भानुमान्॥ उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवं॥

हं

त्य

ततो हमं तर्भवने पितुर्दृत्ता नुरक्षणी। गूढोत्पन्नं सुतं बालं जले कर्णमवासृजं। नूनं तस्यैव देवस्य प्रसादात्पुन
रेवतु। कन्याहमभवं विप्र यथा प्राह स मामृषिः। स मया गूढया पुत्रो जायमानोप्युपेक्षितः। तन्मां दहति विप्रर्षे य
था सुविदितं तव। यदि पापमपापं वा तदेतद्विवृतं मया। तन्मे भयं तु भगवन् व्यपनेतुं त्वमर्हसि। यथास्य राज्ञो
विदितं हृदिस्थं भवतानघ। तं चायं लभतां काममद्यैव मुनिसत्तम। इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदां वरः।
साधु सर्वमिदं भाव्यमेवमेतद्यथात्थ मां। अपराधश्च ते नास्ति कन्याभावगता ह्यसि। देवाश्चैश्वर्यवंतो वै
शरीराण्याविशंति वै। संति देवनिकायाश्च संकल्पाज्जनयंति ये। वाचा दृष्ट्या तथा स्पर्शात्संघर्षेणेति पंच
धा। मनुष्यधर्मो दैवेन धर्मेण हि न दुष्यति। इति कुंति विजानीहि व्येतु ते मानसो ज्वरः। सर्वं बलवतां पथ्यं स
र्वं बलवतां शुचि। सर्वं बलवतां धर्मः सर्वं बलवतां स्वकं॥ ॥इत्याश्रमवासिके ३२॥ ॥व्यासउ०॥ ॥भद्रे द्रक्ष्यसि
गांधारि पुत्रान्भ्रातॄन्सखींस्तथा। वधूश्च पतिभिः सार्द्धं निशि सुप्तोत्थिता इव। कर्णं द्रक्ष्यसि कुंति त्वं सौभद्रं चा
पि यादवी। द्रौपदी पंच पुत्रांश्च पितॄन्भ्रातॄंस्तथैव च। पूर्वमेवैष हृदये व्यवसायो भवन्मम। यदास्मि चोदितो रा

ज्ञा भवत्या पृथयैव च। न ते शोच्या महात्मानः सर्व एव नरर्षभाः। क्षत्रधर्मपराः संतस्तथा हि निधनं ग
ताः। भवितव्यमवश्यं तद्देवकार्यमनिंदिते। अवतेरुस्ततः सर्वे देवभागैर्महीतले। गंधर्वाप्सरसश्चैव
पिशाचा गुह्यराक्षसाः। तथा पुण्यजनाश्चैव सिद्धा देवर्षयोपि च। देवाश्च दानवाश्चैव तथा देवर्षयोम
लाः। त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे। गंधर्वराजो यो धीमान् धृतराष्ट्र इति श्रुतः। स एष मानु
षे लोके धृतराष्ट्रः पतिस्तव। पांडुं मरुद्गणाद्विद्धि विशिष्टतमम च्युतं। धर्मस्यांशोभवत्क्षत्ता राजा चै
व युधिष्ठिरः। कलिं दुर्योधनं विद्धि शकुनिं द्वापरं तथा। दुःशासनादीन्विद्धि त्वं राक्षसान्शुभदर्शने।
मरुद्गणाद्भीमसेनं बलवंतमरिंदमं। विद्धि च त्वं नरमृषिमिमं पार्थं धनंजयं। नारायणं हृषीकेशम
श्विनौ यमजौ तथा। द्विधा कृत्वात्मनो देहमादित्यं तपतां वरं। लोकांश्च तापयानं वै विद्धि कर्णं च शो
भने। यः स वैरार्थमुद्भूतः संहर्षजननस्तथा। यश्च पांडवदायादो हतः षड्भिर्महारथैः। स सोम इह सौ
भद्रो योगादेवाभवद्द्विधा। द्रौपद्या सह संभूतं धृष्टद्युम्नं च पावकात्। अग्नेर्भागं शुभं विद्धि राक्षसं तु

शिखंडिनं। द्रोणं बृहस्पते र्भागं विद्धि द्रौणिं च रुद्रजं। भीष्मं च विद्धि गांगेयं वसुं मानुषतां गतं। एवमेते महा
प्राज्ञ देवा मानुष्यमेत्य हि। ततः पुनर्गताः स्वर्गं कृते कर्मणि निरोभने। यच्च वो हृदि सर्वेषां दुःखमेतच्चिरं
स्थितं। तदद्य व्यपनेष्यामि परलोककृताद्भयात्। सर्वे भवंतो गच्छंतु नदीं भागीरथीं प्रति। तत्र द्रक्ष्यथ
तान्सर्वान्ये हतास्मिन्रणाजिरे॥ ॥वैशं॰॥ ॥इति व्यासस्य वचनं श्रुत्वा सर्वे जनास्तदा। महता सिं
हनादेन गंगामभिमुखा ययुः। धृतराष्ट्रश्च सामात्यः प्रययौ सह पांडवैः। सहितो मुनिशार्दूलै र्गंधर्वै
श्च समागतैः। ततो गंगां समासाद्य क्रमेण स जनार्णवः। निवासमकरोत्सर्वो यथाप्रीति यथासुखं।
राजा च पांडवैः सार्द्धमिष्टे देशे सहानुगः। निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः। जगाम तद
हश्चापि तेषां वर्षशतं यथा। निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान्। अथ पुण्यं गिरिवरमस्त
मभ्यगमद्रविः। ततः कृताभिषेकास्ते नैशं कर्म समाचरन्॥ ॥इत्याश्रमवासिके ३२॥ ॥वैशं॰॥ ॥ततो

निशायां प्राप्तायां कृतसायाह्निकक्रियाः। व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः। धृतराष्ट्रस्तु धर्मा
त्मा पांडवैः सहितस्तदा। शुचिरेकमनाः सार्द्धमृषिभिस्तैरुपाविशत्। गांधार्या सह नार्यस्तु सहिताः समुपाविशन्।
पौरजानपदश्चापि जनः सर्वो यथावयः। ततो व्यासो महातेजाः पुण्यं भागीरथीजलं। अवगाह्याजुहावाथ सर्वा
न्लोकान्महामुनिः। पांडवानां च ये योधाः कौरवाणां च सर्वशः। राजानश्च महाभागा नानादेशनिवासिनः।
ततस्तु तुमुलः शब्दो जलांतर्जनमेजय। प्रादुरासीद्यथा पूर्वं कुरुपांडवसेनयोः। ततस्ते पार्थिवाः सर्वे भीष्मद्रोण
पुरोगमाः। ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः। विराटद्रुपदौ चैव सहपुत्रौ ससैनिकौ। द्रौपदेयाः
ससौभद्रा राक्षसश्च घटोत्कचः। कर्णदुर्योधनौ चैव शकुनिश्च महारथः। दुःशासनादयश्चैव धार्त्तराष्ट्रा म
हाबलाः। जारासंधि र्भगदत्तो जलसंधश्च वीर्यवान्। भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः। लक्ष्मणो
राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः। शिखंडिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः। अचलो वृषकश्चैव राक्ष
सश्चाप्यलायुधः। बाह्लिकः सोमदत्तश्च चेकितानश्च पार्थिवः। एते चान्ये च बहवो बहुत्वाद्ये न कीर्त्तिताः।
सर्वे भास्करदेहास्ते समुत्तस्थु र्जलात्ततः। यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनं। तेन तेन व्यदृश्यंत समु

भा॰आश्र॰
३६

पेतानराधिपाः॥ दिव्यांबरधराः सर्वे सर्वे भ्राजिष्णुकुंडलाः॥ निर्वैरा निरहंकारा विगतक्रोधमत्सराः॥ गंधर्वैरुपगी
यंतः स्तूयमानाश्च बंदिभिः॥ दिव्यमाल्यांबरधरा वृताश्चाप्सरसां गणैः॥ धृतराष्ट्रस्य च तदा दिव्यचक्षुर्नराधिप॥
मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात्॥ दिव्यज्ञानबलोपेता गांधारी च यशस्विनी॥ ददर्श पुत्रांस्तान्सर्वा
न्यचान्येपि मृधे हताः॥ तदद्भुतमचिंत्यं च सुमहल्लोमहर्षणं॥ विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः॥ त
दुत्सवं मदोदग्रं हृष्टनारीनराकुलं॥ आश्चर्यभूतं ददृशे चित्रं पटगतं यथा॥ धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दि
व्येन चक्षुषा॥ मुमुदे भरतश्रेष्ठः प्रसादात्तस्यैव मुनेः॥ ॥इत्याश्रमवासिके ३४॥ ॥वैशं॥ ॥ततस्ते पुरुषश्रे
ष्ठाः समाजग्मुः परस्परं॥ विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः॥ विधिं परममास्थाय ब्रह्मर्षिविहितं शु
भं॥ संहृष्टमनसः सर्वे देवलोक इवामराः॥ पुत्राः पित्रा च मात्रा च भार्याश्च पतिभिः सह॥ भ्रात्रा भ्राता सखा
चैव सख्या राजन्समागताः॥ पांडवास्तु महेष्वासं कर्णं सौभद्रमेव च॥ संप्रहर्षात्समाजग्मुर्द्रौपदेयांश्च सर्व
शः॥ ततस्ते प्रीयमाणा वै कर्णेन सह पांडवाः॥ समेत्य पृथिवीपाल सौहृदे च स्थिताभवन्॥ परस्परं समागम्य

राम
३६

योधास्ते भरतर्षभ॥ मुनेः प्रसादात्ते त्वेवं क्षत्रिया नष्टमन्यवः॥ असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः॥ ए
वं समागताः सर्वे गुरुभिर्बांधवैः सह॥ पुत्रैश्च पुरुषव्याघ्राः कुरवोन्ये च पार्थिवाः॥ तां रात्रिमखिलामेवं वि
हृत्य प्रीयमानसाः॥ मेनिरे परितोषेण नृपाः स्वर्गसदो यथा॥ नात्र शोको भयं त्रासो नारतिर्नायशोभव
न्॥ परस्परं समागम्य योधानां भरतर्षभ॥ समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः॥ मुदं परमिकां प्रा
प्य नार्यो दुःखमथात्यजन्॥ एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः॥ आमंत्र्यान्योन्यमाश्लिष्य ततो ज
ग्मुर्यथागतं॥ ततो विसर्जयामास लोकांस्तान्मुनिपुंगवः॥ क्षणेनांतर्हिताश्चैव प्रेक्षतामेव तेभवन्॥ अवगा
ह्य महात्मानः पुण्यां त्रिपथगां नदीं॥ सरथाः सध्वजाश्चैव स्वानि स्थानानि भेजिरे॥ देवलोकं ययुः केचि
त्केचिद्ब्रह्मसदस्तथा॥ केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन्॥ तथा वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृ
पाः॥ राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून्॥ विचित्रगतयश्चान्या यानवाप्यानरैरिह॥ आजग्मु
स्ते महात्मानः सवाहाः सपदानुगाः॥ गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः॥ धर्मशीलो महातेजाः कुरूणां

आश्र०
३८

हितस्तत्तथा। ततः प्रोवाच ताः सर्वाः क्षत्रियाणि हतेश्वराः। या याः पतिकृतांल्लोकानिच्छंति परमस्त्रियः। ता जा
ह्नवीजलं क्षिप्रमवगाहंत्वतंद्रिताः। ततस्तस्य वचः श्रुत्वा श्रद्दधाना वरांगनाः। श्वशुरं समनुज्ञाप्य विविशु
र्जाह्नवीजलं। विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह। समाजग्मुस्तदा साध्व्यः सर्वा एव विशांपते। एवं क्र
मेण सर्वास्ताः शीलवत्यः पतिव्रताः। प्रविश्य क्षत्रिया मुक्ता जग्मुर्भर्तृसलोकतां। दिव्यरूपसमायुक्ता दि
व्याभरणभूषिताः। दिव्यमाल्यांबरधरा यथासां पतयस्तथा। ताः शीलगुणसंपन्ना वितमस्का गतक्लमाः।
सर्वाः सर्वगुणोपेताः स्वस्थानं प्रतिपेदिरे। यस्य यस्य तु यः कामस्तस्मिन्काले बभूव ह। तं तं विसृष्टवान्व्या
सो वरदो धर्मवत्सलः। तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः। जहृषुर्मुदिताश्चासन्नन्यदेशगता अपि।
प्रियैः समागमं तेषां यः सम्यक् शृणुयान्नरः। प्रियाणि लभते नित्यमिह च प्रेत्य चैव ह। इष्टबांधवसंयो
गमनायाससमागमं। यश्चैतच्छ्रावयेद्विद्वान्विदुषो धर्मवित्तमः। स यशः प्राप्नुयाल्लोके परत्र च शुभां ग
तिं। स्वाध्याययुक्ता मनुजास्तपोयुक्ताश्च भारत। सर्वाचारादयोपेता दाननिर्धूतकल्मषाः। ऋजवः शु

राम
३७

शुचयः क्षांता हिंसानृतविवर्जिताः। आस्तिकाः श्रद्दधानाश्च धृतिमंतश्च मानवाः। श्रुत्वाश्चर्यमिदं पर्वह्यवाप्सति
परां गतिं॥ ॥इत्याश्रमवासिके ३५॥ सौतिः॥ एतच्छ्रुत्वा नृपो विद्वान्हृष्टो भूज्जनमेजयः। पितामहानां सर्वे
षां गमनागमनं तथा। अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति। कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनं। इत्युक्तः
स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान्। प्रोवाच वदतां श्रेष्ठस्तं नृपं जनमेजयं॥ ॥वैशं०॥ ॥अप्रणाशस्स
र्वेषां कर्मणामिति निश्चयः। कर्मजानि शरीराणि तथैवाकृतयो नृप। महाभूतानि नित्यानि भूताधिपतिसंश्र
यात्। तेषां च नित्यसंवासो न विनाशो वियुज्यतां। अनायासकृतं कर्म सत्यः श्रेष्ठफलागमः। आत्मा चैभिः
समायुक्तः सुखदुःखमुपाश्नुते। अविनाशी तथाप्युक्तः क्षेत्रज्ञ इति निश्चयः। भूतानामंतको भावो यथा
सौ संवियुज्यतां। यावन्न क्षीयते कर्म तावत्तस्य स्वरूपता। क्षीणकर्मा नरो लोके रूपान्यत्वं नियच्छति। नाना
भावास्तथैकत्वं शरीरं प्राप्य संहताः। भवंति ते तथा नित्याः पृथग्भावं विजानतां। अश्वमेधे श्रुतिश्चेयमश्व
संज्ञपनं प्रति। लोकांतरगता नित्यं प्राणा नित्यं शरीरिणां। अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव। देवया

नाहि पंथानः श्रुतास्ते यज्ञसंस्तरे। आकूतोयत्र यज्ञस्ते तत्र देवाहितास्तव। यद्वासमन्विता देवाः पशूनां गग
नेश्वराः। गतिमंतश्चते नेत्स्वा नान्यनित्या भयं स्मृता। नित्येस्मिन्पंचके वर्गे नित्ये वात्मनि पूरुषः। अस्य नाना
समायोगं यः पश्यति वृथा मतिः। वियोगे शोचतेत्यर्थं स बाल इति मे मतिः। वियोगे दोषदर्शी यः संयोगं स
विसर्जयेत्। असंगे संगमो नास्ति दुःखं भुवि वियोगजं। परावरज्ञस्तु परो नाभिमानादुदीरितः। अपरज्ञः
परां बुद्धिं ज्ञात्वा मोहाद्विमुच्यते। अदर्शनादापतितः पुनश्चादर्शनं गतः। नाहं तं वेद्मि नासौ मां न च मेस्ति
विरागता। येन येन शरीरेण करोत्ययमनीश्वरः। तेन तेन शरीरेण तदवश्यमुपाश्नुते। मानसं मनसाप्नो
ति शारीरं च शारीरवत्॥ ॥इत्याश्रमवासिके ३६ वैशं॥ ॥स दृष्ट्वा तु नृपः पुत्रान् दर्शनं प्रतिलब्धवान्। ऋ
षेः प्रसादात्पुत्राणां स्वरूपाणां कुरूद्वहः। स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा। अवाप्तवान्नरश्रेष्ठो
बुद्धिनिश्चयमेव च। विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात्। धृतराष्ट्रः समासाद्य व्यासं चैव तपस्विनं।
॥ ॥जनमेजयः॥ ॥ममापि वरदो व्यासो दर्शयेत्पितरं यदि। तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव ते। प्रियं मे

स्यात्कृतार्थश्चास्याम् अहं कृतनिश्चयः। प्रसादादृषिमुख्यस्य मम कामः समृध्यतां॥ ॥सौतिरु०॥ ॥इत्युक्तवचने तस्मि
न्नृपे व्यासः प्रतापवान्। प्रसादमकरोद्धीमा न्नानयच्च परिक्षितं। ततस्तद्रूपवयसमागतं नृपतिं दिवः। श्रीमं
तं पितरं राजा ददर्श जनमेजयः। शमीकं च महात्मानं पुत्रं तं चास्य शृंगिणं। अमात्या ये बभूवुश्च राज्ञस्तान्
स ददर्श ह। ततः सोवभृथे राजा मुदितो जनमेजयः। पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः। स्नात्वा स
नृपतिर्विप्रमास्तीकमिदमब्रवीत्। यायावरकुलोत्पन्नं जरत्कारुसुतं तदा। आस्तीक विविधाश्चर्यो यज्ञो
यमिति मे मतिः। यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः॥ ॥आस्तीकः॥ ॥ऋषिर्द्वैपायनो यत्र पुराणस्त
पसो निधिः। यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ। श्रुतं विचित्रमाख्यानं त्वया पांडवनंदनः। सर्पाश्च भ
स्मसान्नीता गताश्चापचितिं पितुः। कथंचित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव। ऋषयः पूजिताः सर्वे गतिं द
ष्ट्वा महात्मनः। प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनं। विमुक्तो हृदयग्रंथिरुदारजनदर्शनात्। ये
च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये। यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रिया॥ ॥सौतिरु०॥ ॥एतच्छ्रुत्वा
स्वा

द्विजश्रेष्ठाः स राजा जनमेजयः॥ पूजयामास तमृषिमनुमान्य पुनः पुनः॥ भूयः पप्रच्छ तमृषिं वैशंपाय
ननामकं॥ कथावशेषं धर्मज्ञो वनवासस्य सत्तमः॥ ॥इत्याश्रमवासिके परिक्षिद्दर्शनं॥३०॥ जनमे०॥ दृष्ट्वा पुत्रांस्त
था पौत्रान्सानुबंधान्जनाधिपः॥ धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः॥ ॥वैशं०॥ ॥ तदृष्ट्वा महदाश्चर्यं
पुत्राणां दर्शनं नृपः॥ वीतशोकः स राजर्षिः पुनराश्रममागमत्॥ इतरस्तु जनः सर्वस्ते चैव परमर्षयः॥ प्रति
जग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञया॥ पांडवास्तु महात्मानो लघुभूयिष्ठसैनिकाः॥ पुनर्जग्मुर्महात्मानं
सदारास्तं महीपतिं॥ तदाश्रमपदं धीमान् ब्रह्मर्षिर्लोकपूजितः॥ मुनिः सत्यवतीपुत्रो धृतराष्ट्रमभाषत॥
धृतराष्ट्र महाबाहो शृणु कौरवनंदन॥ श्रुतास्ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणां॥ ऋद्धाभिजनवृद्धानां
वेदवेदांगवेदिनां॥ धर्मज्ञानां पुराणानां वदतां विविधाः कथाः॥ मा स्म शोके मनः कार्षीर्दिष्टे न व्यथते बुधः॥
श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात्॥ गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभां॥ यथा दृष्टास्त्वया पुत्रा
स्तथा कामविहारिणः॥ युधिष्ठिरस्त्वयं धीमान् भवंतमनुरुध्यते॥ सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्ज

नः॥ विसर्जयैनं यात्वेष स्वराज्यमनुशासतां॥ मासः समधिकस्त्वेषामतीतो वसतां वने॥ एतद्धि नित्यं यत्नेन पदं र
क्ष्यं नराधिप॥ बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम कुरूद्वह॥ इत्युक्तः कौरवो राजा व्यासेनामिततेजसा॥ युधिष्ठिरमथा
हूय वाग्मी वचनमब्रवीत्॥ अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह॥ त्वत्प्रसादान्महीपाल शोको नास्मान्प्र
बाधते॥ रमे चाहं त्वया पुत्र वने नागपुरे यथा॥ नाथेनानुगतो विद्वन् प्रियेषु परिवर्त्तिना॥ प्राप्तं पुत्रफलं त्व
त्तः प्रीतिर्मे परमा त्वयि॥ न मे मन्युर्महाबाहो गम्यतां पुत्र माचिरं॥ भवंतमिह संप्रेक्ष्य तपो मे परिहीयते॥
तपोयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः॥ मातरौ ते तथैवेमे शीर्णपर्णकृताशने॥ मम तुल्यव्रते पुत्र नचि
रं वर्त्तयिष्यतः॥ दुर्योधनप्रभृतयो दृष्टा लोकांतरं गताः॥ व्यासस्य तपसो वीर्याद्भवतश्च समागमात्॥
प्रयोजनं च निर्वृत्तं जीवितस्य ममानघ॥ उग्रं तपः समास्थास्ये त्वमनुज्ञातुमर्हसि॥ त्वय्य द्य पिंडः की
र्त्तिश्च कुलं चेदं प्रतिष्ठितं॥ श्वो वाद्य वा महाबाहो गम्यतां पुत्र माचिरं॥ राजनीतिः सुबहुशः श्रुता ते भ

रतर्षभ। संदेक्ष्यं न पश्यामि कृतमेतावता विभो॥ ॥वैशंपा॥ ॥ इत्युक्त्वा वचनं तं तु नृपो राजानमब्रवीत्। नमा
मर्हसि धर्मज्ञ परित्यक्तुमनागसं। कामं गच्छंतु ते सर्वे भ्रातरो नुचरास्तथा। भवंतमहमन्विष्ये मातरं च यत
व्रतं। तमुवाचाथ गांधारी मैवं पुत्र शृणुष्व च। त्वय्यधीनं कुरुकुलं पिंडश्च श्वशुरस्य मे। गम्यतां पुत्र पर्या
प्तमेतावत्पूजिता वयं। राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः॥ ॥वैशंपा॥ ॥ इत्युक्तः स तु गांधार्या कुंतीमि
दमभाषत। स्नेहबाष्पाकुले नेत्रे प्रमृज्य रुदती वचः। विसर्जयति मां राजा गांधारी च यशस्विनी। भवत्यां
बद्धचित्तस्तु कथं यास्यामि दुःखितः। न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि। तपसो हि परं नास्ति तपसा
विंदते महत्। ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा। तपस्येवानुरक्तं मे मनः सर्वात्मना तथा। शून्ये
यं च मही कृत्स्ना न मे प्रीतिकरी शुभे। बांधवा नः परिक्षीणा बलं नो न यथा पुरा। पांचालाः सुभृशं क्षीणाः
कन्यामात्रावशेषिताः। न तेषां कुलकर्तारं कंचित्पश्याम्यहं शुभे। सर्वे हि भस्मसान्नीतास्ते द्रोणेन रणा
जिरे। अवशिष्टाश्च निहता द्रोणपुत्रेण वै निशि। चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः। केवलं वृ

राम
४०

ष्णिचक्रं तु वासुदेवपरिग्रहात्। यद्दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नान्यहेतुतः। शिवेन पश्य नः सर्वान्दुर्लभं तव दर्श
नं। भविष्यत्यंब राजा हि तीव्रं प्रारप्स्यते तपः। एतच्छ्रुत्वा महाबाहुः सहदेवो युधांपतिः। युधिष्ठिरमुवाचेदं बा
ष्पव्याकुललोचनः। नोत्सहेहं परित्यक्तुं मातरं भरतर्षभ। प्रतियातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने। इहैव
शोषयिष्यामि तपसेदं कलेवरं। पादशुश्रूषणे रक्तो राज्ञो मात्रोस्तथानयोः। तमुवाच ततः कुंती परिष्वज्य म
हाभुजं। गम्यतां पुत्र मैवं त्वं वोचः कुरु वचो मम। आगमा वः शिवाः संतु स्वस्था भवत पुत्रकाः। उपरोधो भवे
देवमस्माकं तपसः कृते। त्वत्स्नेहपाशबद्धा च हास्येयं तपसः परात्। तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं च नः प्रभो।
एवं संस्तंभितं वाक्यैः कुंत्या बहुविधैर्मनः। सहदेवस्य राजेंद्र राज्ञश्चैव विशेषतः। ते मात्रा समनुज्ञाता राज्ञा
च कुरुपुंगवाः। अभिवाद्य कुरुश्रेष्ठमामंत्रयितुमारभन्॥ ॥युधिष्ठिरः॥ ॥ राजन्प्रतिगमिष्यामः शिवेन प्र
तिनंदिताः। अनुज्ञातास्त्वया राजन्गमिष्यामो विकल्मषाः। एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना। अनु
जज्ञे स कौरव्यमभिनंद्य युधिष्ठिरं। भीमं च बलिनां श्रेष्ठं सांत्वयामास पार्थिवः। स चास्य सम्यग्मेधावी प्र

त्यपद्यत वीर्यवान्। अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ। अनुजज्ञे स कौरव्यः परिष्वज्याभिनंद्य च। गांधार्या
चाप्यनुज्ञाताः कृतपादाभिवादनाः। जनन्या समनुज्ञाताः परिष्वक्ताश्च ते नृप। चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवा
रणे। पुनः पुनर्निरीक्षंतः प्रचक्रुस्ते प्रदक्षिणं। द्रौपदीप्रमुखाश्चैव सर्वाः कौरवयोषितः। न्यायतः श्वश्रुरे वृ
त्तिं प्रयुज्य प्रययुस्ततः। श्वश्र्वा समनुज्ञाताः परिष्वज्याभिनंदिताः। संदिष्टाश्चेतिकर्तव्यं प्रययुर्भर्तृभिः स
ह। ततः प्रजज्ञे निनदः सूतानां युज्यतामिति। उष्ट्राणां क्रोशतां चापि हयानां हेषतामपि। ततो युधिष्ठिरो राजा
सदारः सहसैनिकः। नगरं हास्तिनपुरं पुनरायात्सबांधवः॥ ॥इत्याश्रमवासिके ३८॥ ॥वैशंपा०॥ ॥द्विवर्षो
पनिवृत्तेषु पांडवेषु यदृच्छया। देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरं। तमभ्यर्च्य महाबाहुः कुरुराजो युधि
ष्ठिरः। आसीनं परिविश्वस्तं प्रोवाच वदतां वरः। चिरात्त्वां नानुपश्यामि भगवंतमुपस्थितं। कच्चित्ते कुशलं वि
प्र शुभं नः प्रत्युपस्थितं। के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते। तद्ब्रूहि द्विजमुख्य त्वं त्वं ह्यस्माकं प्रियोति
थिः॥ ॥नारद उ०॥ ॥चिरं दृष्टोसि मे ह्येवमागतोहं तपोवनात्। परिदृष्टानि तीर्थानि गंगा चैव मया नृप॥

॥ ॥युधिष्ठिरः॥ ॥वदंति पुरुषा मे द्य गंगातीरनिवासिनः। धृतराष्ट्रं महात्मानमास्थितं परमं तपः। परिदृष्टस्त्वया
तत्र कुशली स कुरूद्वहः। गांधारी च पृथा चैव सूतपुत्रश्च संजयः। कथं च वर्तते चाद्य पिता मम स पार्थिवः।
श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः॥ ॥नारदः॥ ॥स्थिरीभूय महाराज शृणु वृत्तं यथातथं। यथाश्रु
तं च दृष्टं च मया तस्मिंस्तपोवने। वनवासनिवृत्तेषु भवत्सु कुरुनंदन। कुरुक्षेत्रात्पिता तुभ्यं गंगाद्वारं ययौ नृ
प। गांधार्या सहितो धीमान्वध्वा कुंत्या समन्वितः। संजयेन च सूतेन साग्निहोत्रः स याजकः। आतस्थे
स तपस्तीव्रं पिता तव तपोधनः। वीटां मुखे समाधाय वायुभक्षोभवन्मुनिः। वने स मुनिभिः सर्वैः पूज्यमा
नो महातपाः। त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः। गांधारी तु जलाहारा कुंती मासोपवासिनी। संज
यः षष्ठभक्तेन वर्तयामास भारत। अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो। दृश्यतो दृश्यतश्चैव वने तस्मिन्नृ
पस्य वै। अनिकेतोथ राजा स बभूव वनगोचरः। ते चापि सहिते देव्यौ संजयश्च तमन्वयुः। संजयो नृपतेर्नेता
समेषु विषमेषु च। गांधार्याश्च पृथा राजंश्चक्षुरासीदनिंदिता। ततः कदाचिद्गंगायाः कच्छे स नृपसत्तमः। गंगा

यामापुत्रो धीमानाश्रमाभिमुखोभवत्। अथ वायुः समुद्भूतो दावाग्निरभवन्महान्। ददाह तद्वनं सर्वं परिगृह्य स
मंततः। दह्यत्सु मृगयूथेषु द्विजिह्वेषु समंततः। वराहाणां च यूथेषु संश्रयत्सु जलाशयान्। समाविद्धे वने
तस्मिन्प्राप्ते व्यसन उत्तमे। निराहारतया राजा मंदप्राणविचेष्टितः। असमर्थोपसरणे सुकृशो मातरौ च ते।
ततः स नृपतिर्दृष्ट्वा वह्निमायांतमंतिकात्। इदमाह ततः सूतं संजयं वदतां वरः। गच्छ संजय यत्राग्निर्न
त्वां दहतु कर्हिचित्। वयमत्राग्निना युक्ता गमिष्यामः परां गतिं। तमुवाच किलोद्विग्नः संजयो जयतां
वरः। राजन्मृत्युरनिष्टोयं भविता ते वृथाग्निना। न चोपायं प्रपश्यामि मोक्षणे जातवेदसः। यदत्रानंतरं का
र्यं तद्भवान्वक्तुमर्हति। इत्युक्तः संजयेनेदं पुनराह स पार्थिवः। नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयं।
जलमग्निस्तथा वायुरथवापि विकर्षणं। तापसानां प्रशस्यंते गच्छ संजय माचिरं। इत्युक्त्वा संजयं राजा
समाधाय मनस्तदा। प्राङ्मुखः सह गांधार्या कुंत्या चोपाविशत्तदा। संजयस्तं तथा दृष्ट्वा प्रदक्षिणमथाक
रोत्। उवाच चैनं मेधावीं युंक्ष्वात्मानमिति प्रभो। ऋषिपुत्रो मनीषी स राजा चक्रेस्य तद्वचः। सन्निरुध्येंद्रि

यग्राममासीत्काष्ठोपमस्तदा। गांधारी च महाभागा जननी च पृथा तव। दावाग्निना समायुक्ते स च राजा पिता तव। संज
यस्तु महामात्रस्तस्माद्दावादमुच्यत। गंगाकूलमयादृष्टस्तापसैः परिवारितः। स तानामंत्र्य तेजस्वी निवेद्यैतच्च सर्वशः।
प्रययौ संजयो धीमान्हिमवंतं महीधरं। एवं स विलयं प्राप्तः कुरुराजो महामनाः। गांधारी च पृथा चैव जनन्यौ ते वि
शांपते। यदृच्छया तु व्रजता मया राज्ञः कलेवरं। तयोश्च देव्योरुभयोर्दृष्टानि भरतर्षभ। ततस्तपोवने तस्मिन्समाज
ग्मुस्तपोधनाः। श्रुत्वा राज्ञस्तदा निष्ठां मन्यंते स च न गतावुभे। तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम। यथा च नृप
तिर्दग्धो देव्यौ ते चेति पांडव। न शोचितव्यं राजेंद्र स्वंतः स पृथिवीपतिः। प्राप्तवानग्निसंयोगं गांधारी जननी च
ते॥ ॥वैशंपा॥ ॥ एतच्छ्रुत्वा तु सर्वेषां पांडवानां महात्मनां। निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान्। अंतःपुराणां
च तदा महानार्तस्वरोभवत्। पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिं। अहो धिगिति राजा तु विक्रुश्य भृशदुःखि
तः। ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः। भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते। अंतःपुरेषु च तदा सुमह
न्रुदितस्वनः। प्रादुरासीन्महाराज पृथां श्रुत्वा तथागतां। तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपं। अनुशोचंत ते

सर्वेगां धारी च तपस्विनी। तस्मिन्नुपरते वाक्ये मुहूर्त्तादिव भारत। निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदं॥ ॥इत्या
श्रमवासिके ३९॥ ॥युधिष्ठिरः॥ ॥यथा महात्मनस्तस्य तपस्युग्रे च वर्त्ततः। अनाथस्येव च वने तिष्ठत्स्वस्मासु बं
धुषु। दुर्विज्ञेया गतिर्ब्रह्मन् पुरुषाणां मतिर्मम। यत्र वैचित्रवीर्य्योऽसौ दग्ध एवं दवाग्निना। यस्य पुत्रशतं श्रीम
दभवद्बाहुशालिनः। नागायुतबलो राजा स दग्धो हि दवाग्निना। यं पुरा पर्य्यवीजंत तालवृंतैर्वरस्त्रियः। तं गृ
ध्राः पर्यवीजंत दावाग्निपरिकालितं। सूतमागधसंघैश्च शयानो यः प्रबोध्यते। धरण्यां स नृपः शेते पापस्य म
म कर्मभिः। न च शोचामि गांधारीं हतपुत्रां यशस्विनीं। पतिलोकमनुप्राप्तां यथा भर्तृव्रते स्थितां। पृथामेव च शो
चामि या पुत्रैश्वर्यमृद्धिमत्। उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत्। धिग्राज्यमिदमस्माकं धिग्बलं धिक्प
राक्रमं। क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयं। सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम। यत्समुत्सृज्य सा रा
ज्यं वनवासमरोचयत्। युधिष्ठिरस्य जननी भीमस्य विजयस्य च। अनाथवत्कथं दग्धा इति मुह्यामि चिंतयन्। वृ
था संतर्पितो वह्निः खांडवे सव्यसाचिना। उपकारमजानन्स कृतघ्न इति मे मतिः। यत्रादहत्स भगवान्मातरं सव्य

साचिनः। कृत्वा यो ब्राह्मणच्छद्मं भिक्षार्थं समुपागतः। धिगग्निं धिक्च पार्थस्य विश्रुतां सत्यसंधतां। इदं कष्टतरं
चान्यद्भगवन्प्रतिभाति मे। वृथाग्निना समायोगो यदभूत्पृथिवीपतेः। तथा तपस्विनस्तस्य राजर्षेः कौरवस्य
ह। कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमां। तिष्ठत्सु मंत्रपूतेषु तस्याग्निषु महावने। वृथाग्निना समायु
क्तो निष्ठां प्राप्तः पिता मम। मन्ये पृथा वेपमाना कृशा धमनिसंतता। हा तात धर्मराजेति मामाक्रंदन्महाभये।
भीम पर्य्याप्नुहि भयादिति चैवाभियाचती। समंततः परिक्षिप्ता माता भून्मे दवाग्निना। सहदेवः प्रियस्तस्याः
पुत्रेभ्योऽधिक एव तु। न चैनां मोक्षयामास वीरो माद्रवतीसुतः। तच्छ्रुत्वा रुरुदुः सर्वे समालिंग्य परस्परं। पां
डवाः पंच दुःखार्त्ता भूतानीव युगक्षये। तेषां तु पुरुषेंद्राणां रुदतां रुदितस्वनः। प्रासादाभोगसंरुद्धो अन्वरौ
त्सीत्स रोदसी॥ ॥इत्याश्रमवासिके ४०॥ ॥नारदः॥ ॥नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया। वैचि
त्रवीर्य्यो नृपतिस्तत्ते वक्ष्यामि भारत। वनं प्रविशता तेन वायुभक्षेण धीमता। अग्नयः कारयित्वेष्टिं मुत्सृ
ष्टा इति नः श्रुतः। याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने। समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम। स च

आश्र०
४४

वृद्धस्तदाग्निः वनेतस्मिन्नभूत्किलातेनतद्वनमादीप्तमितिमेतापसाब्रुवन्।सराजाजाह्नवीकच्छेयथातेकथि
तंमयातेनाग्निनासमायुक्तःस्वेनेवभरतर्षभः।एवमावेदयामासुर्मुनयस्तेममानघ।येतेभागीरथीतीरम
याहृष्टायुधिष्ठिर।एवंस्वेनाग्निनाराजासमायुक्तोमहीपते।मात्राचैवपृथयात्वंनृपतिंगतःसपरमांगतिं।गुरुशु
श्रूषयाचैवजननीतेजनाधिप।प्राप्तासुमहतींसिद्धिमितिमेनात्रसंशयः।कर्तुमर्हसिराजेंद्रतेषांत्वमुदकक्रि
यां।भ्रातृभिःसहितःसर्वैरेतदत्रविधीयतां॥ ॥वैराम्॥ ॥ततःसपृथिवीपालःपांडवानांधुरंधरः।निर्ययौस
हसोदर्यःसदारश्चनरर्षभ।पौरजानपदाश्चैवराजभक्तिपुरस्कृताः।गंगांप्रजग्मुरभितोवाससैकेनसंवृताः।त
तोवगाह्यसलिलंसर्वेतेनरपुंगवाः।युयुत्सुमग्रतःकृत्वाददुस्तोयंमहात्मनः।गांधार्याश्चपृथायाश्चविधि
वन्नामगोत्रतः।शौचंनिर्वर्त्तयंतस्तेतत्रोषुर्नगराद्बहिः।प्रेषयामाससनरान्विधिज्ञानाप्तकारिणः।गंगाद्वा
रंनरश्रेष्ठोयत्रदग्धोभवन्नृपः।तत्रैवतेषांकुल्यानिगंगाद्वारेन्वशात्तदा।कर्त्तव्यानीतिपुरुषान्दत्तदेयान्मही
पतिः।द्वादशेहनितेभ्यःसकृतशौचोनराधिपः।ददौश्राद्धानिविधिवद्दक्षिणावंतिपांडवः।धृतराष्ट्रंसमुद्दिश्य

राम
४४

आश्र०
४५

ददौसपृथिवीपतिः।सुवर्णंरजतंगाश्चशय्याश्चसुमहाधनाः।गांधार्याश्चैवतेजस्वीपृथायाश्चपृथक्पृथक्।संकीर्त्य
नामनीराजाददौदानमनुत्तमं।योयदिच्छतियावच्चतावत्सलभतेनरः।शयनंभोजनंपानंमणिरत्नमथोधनं।यान
माच्छादनंभोग्यंदासीश्चसमलंकृताः।ददौराजासमुद्दिश्यतयोर्मात्रोर्महीपतिः।ततःसपृथिवीपालोदत्वाश्राद्धान्य
नेकशः।प्रविवेशपुरंराजानगरंवारणाह्वयं।तेचापिराजवचनात्पुरुषायेगताभवन्।संकल्प्यतेषांकुल्यानिपु
नःप्रत्यागमंस्ततः।माल्यैर्गंधैश्चविविधैरर्चयित्वायथाविधि।कुल्यानितेषांसंयोज्यतदाचख्युर्महीपतेः।समाश्वा
स्यतुराजानंधर्मात्मानंयुधिष्ठिरं।नारदोप्यगमद्राजन्परमर्षिर्यथेप्सितं।एवंवर्षाण्यतीतानिधृतराष्ट्रस्यधीम
तः।वनवासेतथात्रीणिनगरेदशपंचच।हतपुत्रस्यसंग्रामेदानानिददतःसदा।ज्ञातिसंबंधिमित्राणांभ्रातृणां
स्वजनस्यच।युधिष्ठिरस्तुनृपतिर्नातिप्रीतमनास्तदा।धारयामासतद्राज्यंनिहतज्ञातिबांधवः॥ ॥इतिमहाभा
रतेशतसाहस्र्यांसंहितायांवैयासिक्यांआश्रमवासिकंपर्वसमाप्तं॥४१॥शुभमस्तु॥ ॥अतःपरंमौशलंपर्व॥यस्या
यमाद्यःश्लोकः॥ ॥वैराम्॥ ॥षट्त्रिंशेत्वथसंप्राप्तेवर्षेकौरवनंदनः।ददर्शविपरीतानिनिमित्तानियुधिष्ठिरः॥१॥
शाके१६१४अब्धिकूरसभूवर्षेआंगिरसेशुभे॥मासेश्रावणिकेचैवशासरेचगुरोर्निशि॥१॥शुक्लपक्षेचतुर्थ्यांतुशुक्ल
स्तनुश्चमध्यमः॥अनंतात्मिरव्योलिखत्पर्वव्यासाश्रममिदंशुभं॥ ॥श्री॥ ॥छ॥ ॥श्रीः॥ ॥श्रीः॥ ॥श्रीः॥ ॥

राम
४५

[illegible] सधवसपर्वा। [illegible] साहतं [illegible]॥

इदं पुस्तकं शंकराजी [illegible] स्य सहि

शंकरपंडितस्यव्यासाश्रमेदंपुस्तकं १६

[OrderDescription]
,CREATED=24.07.19 14:12
,TRANSFERRED=2019/07/24 at 14:24:59
,PAGES=45
,TYPE=STD
,NAME=S0001107
,Book Name=M-1999-VYASASHARAMPARV
,ORDER_TEXT=
,[PAGELIST]
,FILE1=00000001.TIF
,FILE2=00000002.TIF
,FILE3=00000003.TIF
,FILE4=00000004.TIF
,FILE5=00000005.TIF
,FILE6=00000006.TIF
,FILE7=00000007.TIF
,FILE8=00000008.TIF
,FILE9=00000009.TIF
,FILE10=00000010.TIF
,FILE11=00000011.TIF
,FILE12=00000012.TIF
,FILE13=00000013.TIF
,FILE14=00000014.TIF
,FILE15=00000015.TIF
,FILE16=00000016.TIF
,FILE17=00000017.TIF
,FILE18=00000018.TIF
,FILE19=00000019.TIF
,FILE20=00000020.TIF
,FILE21=00000021.TIF
,FILE22=00000022.TIF
,FILE23=00000023.TIF
,FILE24=00000024.TIF
,FILE25=00000025.TIF
,FILE26=00000026.TIF
,FILE27=00000027.TIF
,FILE28=00000028.TIF
,FILE29=00000029.TIF
,FILE30=00000030.TIF
,FILE31=00000031.TIF
,FILE32=00000032.TIF
,FILE33=00000033.TIF
,FILE34=00000034.TIF

,FILE35=0
,FILE36=0
,FILE37=0
,FILE38=0

,FILE39=0

,FILE40=0

,FILE41=0

FILE42=00000042.TIF
,FILE43=00000043.TIF
,FILE44=00000044.TIF
,FILE45=00000045.TIF
,